CHUNILAL GANDHI VIDYABHAVAN
SURAT.

Manuscripts Library
S.D.P.B.
Coll. No. 777

Title Āryāsaptaśatī

CHUNILAL GANDHI VIDYABHAVAN, SURAT

Shastri Dinmanishankar Pustak-Bhandara

No.: 777 Subject: Kāvya.

Title: Āryāsaptaśatī

Author: Govardhana Scribe:

Date of the work: — Date of the Ms.: —

Place of the work: — Place of the Ms.: —

Size: 11.1" by 5.1" Extent: 4 to 44 foll.

Language: Sanskrit. Script: Devanagari

Remarks: Begins abruptly

पाकेन नूमोदयिताधरमपिनाद्रीयते कासुधा दासी ४६ अकलितवाच्यालंकृतिरनुकूलामल
लितपदनिवेशापि अभिसारिकेव रमयति सूक्तिः सोत्कर्षशृंगारा ४७ अधनिपदग्रहपरमदस
तिहृदयं नवानवाश्रवणां काव्यमभिज्ञसमायां मंजीरं केलिवेलायां ४८ आस्वादितदयिता
धरसुधारसस्यैव सूक्तयो मधुराः अकलितरसालमुकुलो न कोकिलः कलमुदंचयति ४९ बा
लाकटाक्षसूत्रितमसतीनेत्रत्रिभागकृतभाष्यं कविमाणवककाहूती व्याख्यातमधीयते भावं॥
५० मसृणपदरीतिगतयः सज्जनहृदयाभिसारिकाः सुरसाः मदनाद्वयोपनिषदो विशदागोवर्द्ध
नस्यार्याः ५१ वाणीप्राकृतसमुचितरसाबलेनैव संस्कृतं नीता निम्नानुरूपनीरा कलिंदकन्येव ग
गनतलं ५२ आयामिभ्रवातीयंध्वगल्भमनसामवादतायेषां दूतीरहितारवतेनकामिनीमनसि
निविशंते ५३ रतरीतिवीतवसना प्रियेव शुद्धापि वाङ्मुदे सरसा अरसा सालंकृतिरपि न रोचते
शालभंजीव ५४ अथ ग्रंथारंभः अवधिदिनावधिजीवाः प्रसीद जीवतु पथिकजानजायाः

गो० स्वा० दुर्लभ्यवर्त्मन्नैलोस्त्वनैपिधेहि प्रपापालि ५५ अतिवत्सला सुखीला सेवाचतुरा मनो नुकूलाचा।
४ अजनिविनीताग्रहिणी सपदि सपत्नीस्त्वनोन्ने दे ५६ अयि कूलनिचुलमूलोच्छेदनदुःशीलवीचि
वाचाले बकबिषसयंकसारानविराक्षावेरिन्नविनासि ५७ अयि विविधवचनरचनेदर्शसिचं
डं करे समानीय व्यसनदिवसेषु हतिक पुनस्त्वं दर्शनीयासि ५८ अस्तुलानिर्लोकोलांछनम
परित्रातु हीयतामोजः तदपि न मुंचति सचांवसुधाछायामिव सुधांशुः ५९ अतिचापलं वितन्वंत
लिविसल्लिकाम कामिन्यः मुखरयसि स्वयमेतासद्दन्तांकुरिवघंटो ६० अंगेषु जीर्यतिपरं खंज
नमूनोर्मनोनवम्रसरः नपुनरनंतर्गर्भितनिधिनियरामंडलेकेलिः ६१ अंधचमेघसमयेबधि
रं चं बधिरकालम्बालंब्य श्रीकेशवयोः प्रणायी प्रजापतिर्नान्निवासत्वम्: ६२ अपिकोषकारक राम०
रूषेवनेचराणां पुरोगुणोद्धारं यत्नविदार्यविचारितजवरस्त्वं सरवलुतेलामः ६३ अगणितम ४
हिमालंघितगुरुरधनेहःस्तनंधयपविरोधि ईषाकीर्त्तिस्तस्यास्त्वयि रागः प्राणनिरपेक्षः ६४ अ

पराधादधिकं मांव्यथयति तवकपटवचनरचनेयं शास्वायातोवतथास्वीचीवधवेदनायादृक्
६५ असतीलोचनमुकुरे किमपि प्रतिफलतियन्मनोवृत्तिः सारस्वतमपिचक्षुः सतिमिरमिव
तन्नलक्षयति ६६ अन्यमुरेतुवरीयः प्रियवदनेसएवपरिहासः इतरैंधनजन्मायोधूमःसो
गरुसंभवोधूपः ६७ अयि सुभगकुतुकतरला विचरंती सौरभानुसारेण चयि मोहाय वराकी
पतितामधुपीवविषकुसुमे ६८ अयिमुग्धगंधसिंधुरचांकामात्रेणादंतिनोदलिताः उपमु
जते करेणुः केवलमिह मकुणाः करिणः ६९ अतिविनयवामनतनुर्विलंघतेगेहदेहलीन
वधूः अस्योःपुनरारभटीकुकुंभवाटीविजानाति ७० अंतर्गतैर्गुणैः किं द्वित्रा अपि यत्रमा।
रिणो विरलाः सगुणोगतिर्यदसौवनेचरं हरिणामपहरति ७१ अचुलितसंकलविभूषा
प्रातर्बालांविलोक्यमुदितंप्राक् प्रियनिरासिवी स्वयावकमथनिःश्वसितं सपत्नीभिः ७२।
अयि लज्जावति निर्भरनिशीथरतनिःसहांगि सुमुमुक्षे लोचनकोकनदद्वंद्वमुन्मीलय सुभ्र

जानंते ७३ अमिलितवदनमपीडितवक्षोरुहमतिविहृतजघनोरु शपथशतेन भुजाभ्यां केव
लमालिंगितोस्मितया ७४ अतिपूजितनारेयं दृष्टिः क्षतिलंघनक्षमासु तनु जिनसिद्धांतस्थि
तिरिव सवासनाकं न मोहयति ७५ अलमविषयमयलज्जावंचितमात्मानमियमियन्समयं।
नवपरिचितदयितगुणान्योचतिनालपति न्यायनसखीः ७६ अनुरागवर्त्तिनातव विरहे णो
येण साप्तहीतांगी त्रिपुरत्रिगुणेव वगौरी वरतनुरर्धविन्निष्टैव ७७ अन्यप्रवणो प्रेयसि विपरी
तेश्रोतसीव विहितास्याः तरंति मिळंत्यः सविविक्तिनवंति विफलस्य माहात्म्याः ७८ अधिकः स
वैभ्यायः प्रियः प्रियेभ्योद्दृक्षितः सततं सलुठति विरहे जीवः कंठे स्थाल्ममिव संयोगे ७९
अनयनपथे प्रियेन व्यथा यथा दृक्पथ एव दुःखाये ग्लानैव केवलं निद्रितपनाग्निलावास्येक्ष
लति ८० अनिसाम्यो मित्रे पिस्थिति मात्रे गौश्वनं दयन्त्दयितः रहसि व्यपदेशाद्यमर्थड्ब्रा
डाजके लोग्यः ८१ अश्रीषीरपराधान्ममतथ्यं कथयमन्तुखं वीक्ष्य अनिधीयते न किं यदिन

मांनचौराननः कितवः ८२ अन्योन्यमनुस्मोतसमन्यथान्यस्तटात्तटं भजतोः उदितेके
पिनमाद्यस्थानं प्रसमाप्यते यूनोः ८३ अपि चूतवल्लिफलभरनतां गिविषलिकासिसौरभ्ये
।।श्वपचघटर्षे पर्यंकास्तं कीलफलितापि विफलैव ८४ अंजलिरकारिलोकैर्म्लानिरनासैव
रंजिता जगती संध्याया इव वसतिः स्वल्पापि सखे मुखायैव ८५ अगृहीतानुनयां मामुपेक्ष्य
सख्यो गता वतैकाहं च मनं करोषि मयि चेल्लडुपरि वपुरद्य मोक्ष्यामि ८६ उच्छिरागः कित
वो मानी चपलो विरूपकस्त्वमसि मम सख्याः पतसि करे पतयामि यथा तनुर्मवसि ८७ अकू
रुणाकांतरमनसोदयिनितनीरानिरंतरालेयं चामनुधावति विमुखं गंगेव भगीरथं दृष्टिः ८८
अंतःकलुषत्वां सितरसयार्ध्वं गारनालयैव ममा। अप्युन्मुखस्या विहितावरवर्णिनि तनुचयान्
ष्टिः ८९ अपि सरले मरलतरोमंदमुदितद्विपकपोलपालेश्च अन्योन्यमुग्धगेयूव्यतिहारः
कपणामाचष्टे ९० अस्याः करकहषंडितकांडपटप्रकटनिर्गता दृष्टिः पटविगलितनिःकंचु

गो० आ०
६

षासदनेपीयूषधारेव ९१ अस्याःपतिगृहगमनेकरोतिमाताश्रुपिच्छिलांपदवीं गुणगर्वि
तापुनरसौहसतिशनैःशुष्करुदितमुखी ९२ अंकेनिधायकरुणितरचाःशनैरकरुणेतिश
संत्याः मोच्यामिवेणीबंधंकदानवेगंधितैलाक्तैः ९३ अलकेमनलंकृतिमुनगेभूषणा
मुपहासविषयमितरासां कुरुषेवनस्पतिजताप्रसूनमिव वध्यवल्लीनां ९४ अबुधाश्रजा
मात्रपिकयापिगत्यापरंपदमवाप्ताः मंत्रिणइनिकीर्तितेनयबलवटिकाइवजनेन ९५
अतिशीलशीतलतयालोकेषुसखीमृदुप्रतापानः ह्नणावाप्यदह्यमानःप्रतापमस्याः
प्रियोवेद ९६ अन्यासपिगृहिणीतिध्यायन्नभिलषितमखिलमाप्नोति पश्यन्पाषाणम
यीःप्रतिमाइवदेवतोचेन ९७ अनुपेत्यनीचमावंबालकपरितोषगभीरमधुरस्य अस राम०
ःप्रेम्णःपात्रंनभवामिसरितोरसस्येव ९८ अधिवासनमाधेयंगुणमार्गमपेतेनचय ६
घनं कलयमियुवजनमौलिकेतककलिकास्वरूपेण ९९ अपनीतनिखिलतापां

मुनगसकरेणविनिहितांभवता पतिशयनकारणालिकांषधिंवहतिसामाल्लां १०० अगणितगु
णेनसुंदरकचाचारित्रिमप्युदासीनं भवतानन्यगतिःसाविहितावर्त्तेनतरणिरिव १०१ अतुर
करामयापुनरागतयेस्थापितोन्तरीयस्य अप्येकवाससस्तवसर्वयुवभ्योधिकाशोभा २ अर्द्धः
प्राणिस्येकोमृतइतरोमेविधुंतुदस्येव सुधयेवप्रिययापथिसंगत्यालिंगितार्द्धस्य ३ अवधीरि
तोपिनिद्रामिषेणमहात्म्यममृणायाप्रियया अवबोधितोस्मिचपलोबाष्पस्तिमितेनतल्पेन १
०४ अयिशब्दमात्रसाम्यादास्वादितशर्करस्यतवपथिक स्वल्पोरसनाछेदःपुरतोजनहास्य
तामहती ५ अभिनवयौवनदुर्जयविपक्षजनहन्यमानमानापि सूनोःपितृप्रियचाटिनत्रि
भुनगामदंशहिणी ६ अपमानितमिवसंप्रतिगुरुणाग्रीष्मेणदुर्बलंशैत्यं स्थानोस्मुकतरुणी
स्तनकलशानिवकंपयोविशति ७ अजसयतिगात्रमखिलंकेशांमोचयतिलोचनंहरति स्वा
पस्वप्नेयान्ममम्मोकुंनददातिशायनीयं ८ अंसावलंबिकसलनकचमिदमभिषेकधवलनख

गी०आ०
७

रेषं धौताधरनयनंवपुरखमनंगस्यनिशितं ९ अविनिहितंविनिहितमीव मुसछेषुवारवा
मद्भाः नुपदर्शयंतिहृदयंदर्पणबिंबेषुवदनमिव १० अलिलजकयाचयेवप्रकटः प्रेयान
कारिनिर्गतोपि प्रासादमौलिरूपरिभ्रसरंत्यावैजयंत्येव ११ अन्योन्यगुणग्रथनायोगा
कःपदार्पणोगुरुभिः खलमपितुदंतिमेदीभूतंमध्यस्थमालंब्य १२ अननुग्रहेणानतथाम
ययतिकटुकूजितैर्यथापिशुनः रुधिरादानादधिकंदुनोतिकर्णौकिणान्मधुकः १३ अयेलभि
मायाश्वान्महतापिपिधियतेनहिमहिम्ना वामनयतित्रिविक्रममभिदयतिदशावताराविदः।
१४ अंकेस्तनंधयस्तवचरणोपरिचारिकाः प्रियः दृष्टे असिकिमलभ्यमाधिकंगृहिणीय
हांकसेवाजो १५ अयरक्तस्तःकूजितमामलिनमक्लिलोलितोमौलिः आसादितमि
वचुंबनसुखमस्यवोपीतरुणाभ्या १६ अतिरसनेनभुजोयंवृतिविवरेणप्रवेशितःसद
नं दयितास्पर्शोल्लसितोनागच्छतिवर्त्मनातेन १७ अंबरमध्यनिविष्टंतवेदमतिचपा

राम०
७

लमलघुनतटं चातकइवनवमभ्रंनिरीक्ष्यमाणोनतृप्यामि १८ अयमंधकारसिंधुरमाराक्रां
तावनीभराक्रांतः उन्नतपूर्वाद्रिमुषःकूर्मःसंध्यात्समुद्वमति १९ अंतर्भूतोनिवसतिजडेज
डःग्राम्योस्महासिहरिणइव अजडेनाभीवतपनेसतुप्रविष्टोपितिरस्करोति २० अगणितज
नापवादाचल्याणिस्पर्शोहर्षतरलेयं आयास्यतोवराकीद्वारस्यनल्पंचकल्पयति २१ अ
ष्यैकवंशजाजनुषोःपवनयतपूर्णचतुच्छतामाजोः ज्याकार्मुकयोःकश्चिद्गुणान्तृतःकश्चिदपिन
तां २२ अभिनवकेलिक्लांताकलयतिबालाक्रमेणघर्मांभिः यामपोयितुंनमिताकुसुमा
स्रधनुर्लतेवमधु २३ अविरलपतिताश्रुवपुःपांडुस्निग्धंतवोपनीतमिदं स्नानधौतमाज्य
मिस्मरज्वरदाहव्यथांहरति २४ अंतर्निपतितगुंजगुणारमणीयस्मकाप्तिकेदारः निजगो
पीविनयव्ययखेदेनविदीर्णहृदयइव २५ अमुनाहतमिदमिदमितिरुदतीप्रतिवेश्मिनिंग
मंगमियं रोषमिपदलितलगृहिणीदर्शयतिपतिपुरतः २६ इत्याकारप्रज्या ग्रांतर

गो०स्रा० मपिबहिरिवहृदयंजनयितुंरमणस्योषतःसततं असतीसकलविमुक्तिःकाचघटीवित्रयंवेद॥
६ २७ आलोकएवविमुखीकविदमिदिवसेनदक्षिणाभवसि छायेवतदपितापंचमेवमेहर
सिमानवति २८ आज्ञाकाकुर्याचाटुःकोपोहसितंचशुष्करुदितंच इतिनिधुवनपांडित्यंध्या
यन्नस्यानन्दयामि २९ आज्ञापयिष्यसिपदंदास्यसिदयितस्यनिरसिकिंचरसे असमय
मानिनिमुग्धेमांकुरुभ्वपंकरुहेम ३० आसाद्यमंगमनयाद्यूतेविहितामिरुचितकेलिपणो
॥निस्मारयताध्यानितिकपटरुषोत्सारिताःसख्यः ३१ आदरणीयगुणासखिमहतानिहि
तासितेनविरसिचं तवलाघवदोषोयंसोथपताकेवयच्चलसि ३२ आर्द्रमपिस्तनजघ
नाभिरस्यतचितयेतदुन्मुक्तं स्वच्छवासमवासमपिचांतपनांगुष्ठकंपिबति ३३ आरोपि एम०
ताशिलायामस्मेवचंस्थिरास्भवेतिमंत्रेण मन्नापिपरिणायापादेनारमुखंवीक्ष्यहसितेव॥ ८
३४ आयातियातिखेदंकरोतिमधुहरतिमधुकरीवान्या अधिदेवताचमेवमभीरिवकरुजस्य

ममममनसः ३५ आसाद्यदक्षिणांदिशमविलंबंत्यजतिचोत्तरांतरणिः पुरुषंहरंतिकांताः
प्रायेणाहिदक्षिणाइव ३६ आदानपानलेपैःकाश्चित्फलोपतापहारिण्यः सदसिस्थितैव
सिद्धौषधिवल्लीकापिजीवयति ३७ आंदोलनलोलकेशीचलकांचीकिंकिणीगणाक्वणितां
॥स्मरसिपुरुषायितांतांस्मरचामरकेतुयष्टिमिव ३८ आक्षिपसिकर्णमस्तृणाबलिरपिबध
स्वयात्रियामध्ये इतिजितसकलवदान्येतनुदानेलक्षसेतनि ३९ आक्षेपचरणलंघनके
शग्रहकेलिकुतुकतरलेन स्त्रीणांपतिरपिगुरुरितिधर्मेनभाविताखुतनुः ४० आगच्छ
तानवेक्षितदृष्टेनार्थीचराटकेनेव मुषितास्मितेनजघनांशुकमपिवोढुनचाकेवयाक्षेनति
वा ४१ आकुंचितैकजंघंदत्तैकोरुगोपितावेरु सुतनोःश्वसितकमनमदुदरस्फुटना
न्निद्रायनमिदं ४२ आदायधनमनल्पंददानयासुभगतावकेवासः मुग्धारजकगृहिण्या
कृतादिनैःकतिपयैर्निस्वा ४३ आस्तांवरमवकेशीमादोहदमस्यरचयपूगतरोः एतस्मात्क

गो० आ० लितादपिकेवलमुद्वेग ४४ आराध्यमध्यमथनं सहस्त्वयि चाद्विजिक्कममरैर्यत् उचितस्त
९ त्यरिणामोविषमंविषमेवयन्क्तातं ४५ आवर्जितालकालिम्पामोक्तंपिल्लनार्पितैक्सुजं त्वा
यनंरतिविवत्रातनोः स्मरामिनिशिथिलांशुकंतस्याः ४६ आम्नाकुरोयमरुणाच्चयामलरुचिरस्ध्वे
निर्गतःसुतनु नवकमठपर्परपुटान्मूर्द्धगतःस्फुरति ४७ आमंगुराग्रवक्कगुणादीर्घास्वाद
प्रत्नाप्रियादृष्टिः कर्षतिमनोमदीयंक्कटमीनंवडिशारज्जुरिव ४८ आलपयथायथेष्ठमियु
क्तंतवकिमुपरोधयसि स्त्रीजातिलांछनमसोजीवितंकामसखीसुजग ४९ आस्वादितोसि
मोहात्कतविदितावदनमाधुरीमवतः मधुलिप्सल्लुररसनाच्छेदायपरंविजानासि ५० आ
रूढ्सिन्यककटकंकेनतवप्रकृतिकोमलंसुभगे धन्येनभुजमृणालंग्राह्यंमदनस्यराज्यमि राम०
व ५१ आरूढ्यद्वरमणीतरौबक्केव्याप्रकाशयंतीसं वातप्रतीष्छनपटीवहित्रमिव ९
हरसिमांसुतनु ५२ आयासःपरहिंसावैतंसिकसारमेयतवसारः चामयसार्यविना

स्यःकुरंगशावोधुनैवान्यैः ५३ आनयतिपथिकतस्याऽहप्रापयलिवात्मानं उपकल्पमगोपि
कोमलकलमाबालिकबलनोत्तरल ५४ आसीदेषयदार्द्रःकिमपितदाकिमपमाहतोप्याह्ल
निष्ठुरस्नावारधुनाकरंनिरस्यतिसखिपटहइव ५५ आज्ञाकरस्त्वपाणिमवताडनसहनस्त्वं
सत्यमहमस्याःनतुचालचामितलेयंप्रियेतरंवक्तुमापिवेद ५६ आधायदुग्धकलशामंथानंक्षी
रदोलिनागोपी अग्राह्यपारिजातादेवदोषंनिवेदयति ५७ आस्तांमानःकथनंसखीपुवाम
यिनिवेद्यदुर्विनये शिथिलितरतिगुणगर्वामिमायिसालज्जितासुतनुः ५८ आवर्त्तैरातर्प
णशोभांडिंडीरपांडुरैर्दधती गायतिसुखरितसलिलाप्रियसंगममंगलंसुरसा १५९ इत्या
कारव्रज्या इयमुक्तिहरतीनेत्रनिकोचंचविदधतीपुरतः नविजानीमःकिंतववदति
सपत्नीवदिननिद्रा ६० इदमुत्नयनिनिसंततहारगुणांतर्गतैककुचमुकुलं गुलिकाधनु
रिवबालावपुःस्मरःश्रयतिकुतुकेन ६१ इहनिशापरिशिखालंबिनिनोदरतरलघपुषि

गी०श्री० ततनुहरिरोतिवारहरिरो पश्यामिलषतिपतितुंविहगीनिजनीडमोहेन ६२ इस्तुनंदी
प्रवाहोद्भूतंमानयहस्वतेमुतनु सूलतिकाचतवेयंनसेरसमधिकमावहति ६३ इंदीरि
१० वास्यपुरतोयद्विमुखीसापवारणाञ्नमसि तत्कथयकिंनुदुरितंसखिचयान्नायययैवकृता
६४ इहकपटकुतुकतरलितदृन्विश्वासंकुरंगकिंकुरुषे तवरन्नसतरलितेयंव्याधवधू
बालिर्धावलते ६५ इहवहतिवक्रमहोदधिविभ्रूषणामानगर्वमियमुर्वी देवस्यकमठमू
र्त्तेर्निर्दिष्टमपिनिषिद्धमाप्नोति ६६ इर्ष्यारोपकलितोनिजपतिसंगंविचितयंत्तस्याः च्युत
वसनजघनमावनसांद्रानंदेननिर्वामि ६७ ईश्वरपरिग्रहोचितमोहोस्यांमधुपकिमुधा
पतसि कनकाभिधानसारावीतरसाकितवकलिकेयं ६८ ईषद्वक्त्रोषदवजडिमाक्षिश्चि पंम०
रगतमात्रएवचिरमंगैः नवयौवनेचतन्वीनिषेव्यतेनिर्भरंवामी ६९ इतीकारश्रज्या॥ ॥ १०
उल्लसितलूधनुषानवृष्टयुनालोचनेनरुचिनेनरांगी अचलाश्रपिनमहांतःकैवाचलमा

वमानीताः ७० उपनीयपल्लितंवेभुजंगमुच्चैरलंभिविबुधैःश्रीः एकःसमंदरगिरिःसा
खिगरिमाणंसमुद्वहतु ७१ उल्लसितलांछनोयंज्योत्स्नावर्षीसुधाकरःस्फुरति आसा
कल्लष रणाःत्राकटइवध्रकटितश्रीः ७२ उपचारानुनयास्तेकितवस्योपेक्षिता
ःसखिवचसा अधुनानिष्ठुरमपियदिसवदतिकलिकेतवाघ्रामि ७३ उपसिपरिक्त
यंत्यामुक्तादामोपवर्तितलानीतं पुरुषायितवैदग्ध्यंव्रीडावतिकेनकलितंते ७४ उ
ज्जागरितस्त्राभितदंतुरदलरुद्धमधुकरप्रकरे कांचनकेतकिमातवविकसतुसौरम्य
संभारः ७५ उड्डीनानामेषांप्रसादात्तरुणिपक्षिणांपंक्तिः विस्फुरतिवैजयंतीपवन
छिन्नापविद्धेव ७६ उल्लसितलूःकिमतिक्रांतंचिंतयसिनिस्तरंगाक्षि रूढाउपचार
विरसःपाकःप्रेम्णोगुडस्येव ७७ उद्विग्नयनिसरंतीसखिप्रियंकपटकोपकुटिलभ्रूः
॥एवमवतंसमाक्षिपदाहतदीपंयथापतसि ७८ उदितोपितुहिनगहनेगगनप्रांतेनदी

गो०आ० प्यतेतपनः कविनद्युतपूरपूर्णेन्द्राराविन्निरसिप्रदीपइव ७९ उत्क्रमनोपानिवेशानन्नायन
पराहृत्तिवचनरचनेषु अनिशंसमोहयतिमांहृल्लग्नः श्वासइवदयितः ८० उज्झितसौ
११ भाग्यमदस्फुटयोश्चानंगमीतयोर्यूनोः अकलितमनसोरेकादृष्टिर्हृत्तानिमग्नार्था ८१ उ
त्तमभुजंगसंगमनिस्पंदनितंबचापलस्तस्याः मंदरगिरिरिवविबुधैरितस्ततःकृष्यतेकां
यः ८२ उपनीयकलमकुडवंकथयतिसभयमशिकिस्सकहलिकः शोणांसोमार्द्रनिर्जंव
धूस्तनेव्याधिमुपजातं ८३ उन्मुकुलितार्धरपुटेनूतिकणात्वासमीलिताद्यक्षि भूमेपि
निहविरमन्त्रमरोयंश्वसितमनुसरति ८४ उपरिपरिप्लवतेममबालेयंगृहिणीहंसमा
लेव सरसइवनलिननालाचमात्रायंप्राप्यवमसिपुनः ८५ उत्कंपघर्मपिच्छिलदोः राम०
साधिकहस्तविच्युतस्त्रीरः निवमाश्चास्नेसुतनुस्तनयोस्तवकंचवलांचलयोः ८६ उल्ल ११
सबाकुरंदन्निनिभुजमूलंचूतमुकुलममसरख्या आलप्यमाणराजतिनवतःपरमुत्पद

लानः ८७ उद्वृत्तचकंस्तनिहितोहृदयंचालयतिजघनलग्नायः आतिनिम्नमध्यसंक्रमस
ललिनस्तरलितवहारः ८८ उच्छ्वसितचातदीधितिकलापकंवेस्फुरंतितारोषाःकुसु
मायुधविधृतधनुर्निर्गतमकरंदबिंदुनिभाः ८९ उपनीयप्रियमसमयविदंचमेदग्ध
मानमपनीय नमोपक्रमएवरुणादेहलीक्वलितासि ९० उन्नमवनितैकगतिःक
रीवसरसीपयःसखीधैर्यं आंदोलितोरुणाचेहस्तेनेवस्मृत्वानहरसि ९१ ऊढासु
नातिवाह्यपृष्ठेलग्नापिकालमचलासि सर्वंसहेकगेरचचःकिमंकेनकमठस्य ९२
इत्यूकारव्रज्या ऋजुनानिधेहिचरणौपरिहरसखिनिखिलनागराचारं इहडाकिनी
तिपल्लीपतिःकटाक्षेपिदंडयति ९३ ऋषभोत्रगीयतइतिश्रुत्वाचास्वरपारगावयंश्वाघाः।
कोवेदगोष्ठमेतमोच्यानौविहितकुक्कुमानौ ९४ इतिऋकारः एकोहरःप्रियाधरगुण
वेदीदिविषदोपरेमूढाः विषममृतंवासममिमितियःपन्नगरलमेवपपौ ९५ एष्यतिमां

पुनरयमितिगमनेयदमंगलंमर्माकारि अधुनातदेवकारणमवस्थितौदग्धगेहपतेः॥
९६ एकैकशोभुवजनंविलंघमानारुनिकरमिवतरला विश्राम्यतिभुजगचामंगुलिरा
घाघमेरुमिव ९७ एकःसएवजीवतिमद्धृदयशून्योपिसहृदयोराकुः यःसकलल
घिमकारणमुदरंसनविभर्निभुःपूरं ९८ एकेनचूर्णांकितलमपरेणाकरेणविबुकमुन्नम
यत् पश्यामिवांम्पधौतश्रुतिनगरवारितवदनं ९९ एकंजीवनमूलंचंचलमपिता
पतयंतमपिसततं अंतर्वहतिवराकीसाचांनामेवनिश्वासं १०० एकंवदतिमनोम।
मयामिनयामीतिहृदयमपरंमे हृदयद्वयमुचितंतवसुंदरिकृतकांतचित्रायाः १ ए
रंडपत्रत्रायनाजनयंसीसेदमलघुजघनतटो धूलिपुटीवमिलंतीस्मरकृरंहरतिहलिक
वधूः २ इत्येकारव्रज्या केलिनियमंसखीमिवनयतिनवोढांस्वयंनमांसजते इष्टं
गृहिणीमयैसुवतिप्रतिवेशिनाहसितं ३ कालक्रमकमनीमक्रोडेयंकेतकीतिकांतं

का दृष्टिर्यथायथास्यात्तथातथाकंटकोत्कर्षः ४ कनकस्यापमदीयस्मासद्धनिदत्तकर्ण
किंतीत्रैः विध्यसिमांनिश्वासैःस्मरःशरैःन्नाद्वेधीव ५ कमनिर्मोकिङुकुलःकालंकरणा
यफणममणिश्रेणी कालियभुजंगगमनाद्यमुनेविश्वस्यगम्यासि ६ किंचिन्नवाल्मयोक्तेन
सप्रसादानिवेशितारदृष्टिः मयिपदपतितेकेवलमकारिशुकपंजरोविमुखः ७ कुतिह।
सितहस्ततालंमन्मथतरलैर्विलोकितांयुवभिः क्लिष्टःक्लिष्टोनिपतन्नंगेनंर्नयतिमृंग
स्तां ८ कमलमुखिसर्वतोमुखनिवारणंविदधदेवनृपयति रोधोरुद्धरसाल्तरंगिणीस्त
रलनयनाश्च ९ कितवप्रपंचितासानवतामंदाक्रमंदसंचारा बकुलदायैरपिसंप्रतिपा
त्राकषारीवनायाति १० कःश्लाघनीयजन्मामाघनिशीथेपियस्यसौभाग्यं आलेयाति
लदीर्घःकथयतिकांचीनिनादोयं ११ किमत्राकतीयंप्रेमणाःफणिनःकथयापियाविमि
तिस्म सागिरिशानुजंगमफणोपधानायनिद्राति १२ कृत्रिमकनकेनेवप्रेमणामुषिता।

गो०श्रा० स्ववारवनिताभिः जघुरिवविनविनाचान्केन्योजनहास्यतामहती २३ किंपर्वदिव
२३ समार्जितदंतौष्टिनिजंवपुर्नमंडयसि नवांत्यक्तातिपर्वल्लिपिमधुरामिक्षुयष्टिमिव २४
कष्टंसाहसकारिणितवनयनार्धेनसोधनिस्पृष्टः उपवीतोदपिविदितोनद्विजदेहस्तप
सीते २५ केन्नोपितन्यमानेमिलितेयंमांक्रमोदयत्येव रौद्रेनत्वेपिनमसुरापगावारि
वृष्टिरिव २६ कूपघ्नावानापरमुचितमपांपदंवंधुनंमन्ये याःत्राक्यंतेलब्धुंनयाथिवें
नामिविगुणेन २७ कररुहशिखानिपानत्यांचाविश्रांतरजनिदुरवाप रविरिवयत्रो
ल्लिखितःकृत्योपिलोकस्यहहृरासिदृत्वां २८ किंकरवाणिदिवानिशामपिलग्नासहज
शीतलप्रकृतिःहंतसुषयामिनप्रियमात्मानमिवात्मनश्छाया २९ केशैःशिरसोगरि
मामरणंपीयूषकुंडपातेन दयितवहनेनवक्षसियदिसंनात्ताहृदिमचिकित्स्यं॥ राम०
३० किंचिककर्कशतामतुरसंप्रदायस्यलिप्सर्गमधुरोमे इत्थोरिवतेसुंदरिमानस्यग्रंथी २३

रपिकाम्यः ३१ केनगिरित्रास्यदत्ताबुद्धिर्भुजगंजटावनेर्यापितुं येनरतिरत्नसकांताकरा
कराकर्षणांमुषितं ३२ करचरणकांचिहारप्रहाररसमविचिंत्यबल्यगृहीतकचः प्रणयीचुं
बतिदयितावदनंस्फुरदधरमकृणान्हं ३३ कुरुतांचापलमधुनाकलयतुसुरसासियादृगपि
तदपि सुदरिहरीतकीमनुपरिपीतावारिधारेवा। ३४ कज्जकितिलककलंकितमुर्षेच
केशागलितसलिलकणाकेशि नवविरहदहनतूलोजीविमितव्यस्त्वयाकतमः ३५ कृष्णा
नुरक्तयोपिहिपरोपकारंत्यजेतिनमहांतः तृणमात्रजीवनाश्चपिकरिणोदानइवार्द्रकरा
ः ३६ किंहसथकिंप्रधावथकिंजनमाकयथबालकाविफवंलं तदयंदर्शयतियथारिष्ट
कंवेमुनात्नगृहे ३७ कातरताकेकरितस्मरलज्जारोषमसृणमधुराक्षी मोक्तुंनमोक्तु
मथवावलतेसावर्धलघ्नरतिः ३८ केतकगर्भेगंधादरेणाहूरावमीकृतमुपेताः मदनस्या
दनवाजिनइवमधुलिमाददते ३९ कोवक्रिमागुणाःकेकाकांतिःशिशिरकिरणलेखा

नां श्रंतःप्रविश्यप्रयासामाक्रांतंपश्चविशेषेण ३० कृतविविधमथनयत्नःपरान्नवाप्य
नुःसुरासुरयोः इच्छतिसौभाग्यमदास्स्वयंवरेणश्रियंविष्णु ३१ किंपुत्रिगंडशैलभ्रमेणन
वनीरदेषुनिद्राति श्रनुभवचपलाविलसितगर्जितदेशांतरभ्रांतीः ३२ कांतःपदेनहं
तइतिसरलामपराध्यकिंप्रसादथ सोप्येवमेवसुलभःपदप्रहारप्रसादाकि ३३ कर्णा
गतेयममोघाद्दष्टिस्तवभ्रूक्किरिंद्रदत्ताच मानामादित्तिविजयाक्कचिदपिनापार्थपतितेयं
३४ केनायमिकिमितिहत्तीर्यदत्राकंसुमुखितवकटाक्षेण कामोपितत्रसायकम
कीर्निशांकीनसंधत्ते ३५ कोवेदमूल्यमस्यद्यूतेप्रगुणपणापितस्यविधोः पतिविजये
यत्प्रतिपणामधुरंधरनंदिनीविदधे ३६ कुपितोचरणप्रहरणान्नयेनमुंचामिनखलुच
ण्डिकां अलिरनिलचपलकिसलयताडनसहनोलतांनजते ३७ कोपात्कृष्टभ्रूस्मर
चापासनेसंवृणुप्रियेपतनः छिन्नज्यामधुपानिवकज्जलमलिनाश्रुजलबिंदून् ३८

कामेनापिनूनेत्वंकिमुहृदयमपारिव्राजवनितानां मूढविविधप्रहारोच्छूनमिवानातिथ
वक्त्रः ३९ किंपरजीवेदोव्यमिविस्मयमधुरान्निगच्छसखिद्दरं स्वहिमधिचवरमुरगम
हीखेलयःतुनिर्विघ्नः ४० करचरणेनप्रहरतियथायथांगेषुकोपतरलाक्षी रोषयुत
परुषवचनैस्तुधातथाप्रेयसीरसिकः ४१ कस्तांबिंदतिकुपतिकःस्मरफलकस्यवल्गंक
मुग्धः कोभवतिरत्नकंटकप्रमृतेकस्यारुविरुदेति ४२ कोपवतिपाणिलीलांचंचचूतांकु
रेचपित्रमति करकंपितकरवालेस्मरइवसामूर्छितामुतनुः ४३ कोलीनादलमेतोन
जामिनकुलंस्मरःप्रमाणायति तद्भावनेनभजतोममगोत्रस्खलितमनिवार्यं ४४ कुत
इहकुरंगनाविकककेदारेकलममंजरीत्यजसि तृणबाणास्तृणधन्वातृणरचितःकपट
पुरुषोयं ४५ खलसख्यंप्राङ्मधुरंवयोंतरालेनिदाघदिनमंते एकादिमध्यपरिणतिर
मणीयासाधुजनमैत्री ४६ गुणमधिगतमपिधनवान्चिरान्नाद्रायतिरकृतिदरिद्रः मत्र

गो०स० यतिरञ्जुमन्नसिपूर्णः कुंभः सखि न तुच्छः ४७ गुरुरपि लघूपनीतो न निमज्जति नियतमात्म
येमहतः वानरकरोपनीतः सैखि न तुच्छः ४८ लोमकरालयेस्येव ४८ गौरीपतेर्गरीयोग
१५ रलंगचागलांतिकेजीर्णे जीर्यति कर्णोमहतां दुर्वादोनान्यमपि विशति ४९ गृहपतिपु
रतोजारंकपटकथाकथितमन्माथावस्थं प्रीणयति च पीडयति च बाला निश्वस्यनिश्वा
स्य ५० गतिगंजितवरयुवतिः करीकपोलोकरोतु मदमलिनो मुषवंधमात्रसिंधुरली
बोदर किंमदं वहसि ५१ गेहिन्याः श्रुण्वंती गोत्रस्खलितापराधतो मानं स्निग्धां प्रियेस
गर्वा सखीषु बाला हृत्वं दिशति ५२ ग्रीष्मसमये समयेस्मिन्विनिर्मितं कलय केलितरुमूले
।स्खलमालवालवलयछलेनकुंडलितमिवस्रोतः ५३ गुणाबद्धचरणाइतिमालीला विह राम०
गंविमुंचसखिमुग्धे स्मिन्वल्लयितप्ताखेटोनगुणायंत्रणांत्रुटति ५४ गुरुगर्जसांद्र १५
विकक्रयमुग्धिनकर्ण चक्षुषां पुरतः बालाचुंबतिजारं वक्त्रादधिको हि मदनेषुः ५५ गृही

णीगुणोपुगणितोविनयः सेवा विधेयतेति गुणाः मानः प्रभुता वाम्यं विभूषणं वामनयना
नां ५६ गुणामांतरमगुणं वा लक्ष्मीर्गंगा च वेद हरिहरयोः एकापदेपिरमते निवसति निहि
ता शिरस्यपरा ५७ गवाजीवितसंज्ञा यमन्यस्तः सोदुमति विरादिरहः स्वकरुणादिसौ
पुनरपिसुरतदुरन्याममस्याकं ५८ गोत्रस्खलितप्रश्रेप्युत्तरमतीत्रीत नंदचा निश्वस्यमो
घरूपेस्वव पुषि निहितं तया चक्षुः ५९ गंधयाहिणि ग्रालोन्मीलन्नियामनिहितनिखिलां
गि उपनुकमुकमुकुरुहन्नातेधुनान्यमरिनिल्लमसि ६० गुरुषुमिलितेषु शिरसा प्रणाम
सिल्यपुपूत्तातासमेषुसमा उचितस्तासितुले किं तुलयसि गुंजाफलैः कनक ६१ गेहिन्या
क्रीयमाणोनिरुध्यमानेन वोढया पुरतः मम मनो का धिनयार्पितपद इव हृदयं द्वियानवति
६२ गुणाकर्षणायोग्योधनुषइवेकोपि लक्ष्मलामाय जूतातंतुनिरिव किं गुणो विम
त्तसि हैवक्रिनिः ६३ गायति गीते त्रांसमदिवं त्रीवादयतिसा विपञ्चीषु पाठयति पंजरस्थ

गो०आ०
९६

कोस्त्ववसंवादाद्दूरं बाला ६४ गणयति न मधुव्ययमयमविरतमापिबति मधुकरः कुमुदं सौना
ग्यमानवान्यरमस्मृतिक्रमणायेवंदः ६५ गुणविधुतासखिनिश्वसितथैवदेहेनकिंतुहृदयं
ते हृतममुनामालायाःसमीरणेनेवसौरभ्यं ६६ गुरुसदनेनेदीयसिचरणागतमपिचमूका
यापितया नूपुरमपास्यपदयोःकिंनप्रियमीरितंप्रियया ६७ ग्रथिलतयाकिमिन्दोःकि
मफलंश्रोनमवंतिगीतस्य किमनार्जवेनद्रविणःकिंदारिद्र्येणदयितस्या ६८ गेहिन्या
चिकुरग्रहसमयससीत्कारमीलितदृशापि बालाकपोलपुलकंविलोक्यनिहतोस्मिशिर
सिपदा ६९ गुरुपक्ष्मजागरारुणमूर्णान्तारंकथंचिदपिवलते नयनमिदंस्फुटनखपदति
वेदानेकोपकौटिल्यं ७० इतिगीकारभ्रान्त्या घटितजघनेनिपीडितपीनोरुन्यस्तनिखि
लकुचभारं आलिंगत्यपिबालावदत्यसौमुंचमुंचेति ७१ घटितपलाशकपाटंनिद्रानिद्रा
मुषितोहिद्वारतेपस्याः उत्कागरेणाकैरवबतिव्यक्यारक्षितुंलक्ष्मीः ७२ घूर्णतिविप्रलब्धाः

राम०
९६

स्नेहापायात्प्रदीपकलिकाश्च यातःस्थितपांथस्त्रीहृदयंस्फुटतिकमलंच ७३ चपलस्य
पलितलांछितचिकुरंदयितस्यमौलिमवलोक्य खेदोचितेपिसमयेसंमदमेवाददेगृहिणी।
७४ चंडिप्रसारितेनस्पृष्टानभुजेनापिकोमनांभवती तृष्णामिपंकिलामिवकदीनलिनना
लेन ७५ चपलभुजंगाभुक्तोज्झितग्रीतजगंधवहनिश्वासक्रांत अपराद्धांपूरयितुंप्रत्यू
षसदागतेगच्छ ७६ चिरपथिकद्राघिमभिलदलकलताग्रोवलावलियथिता करतोये
वमृगाक्ष्याघ्टष्टिरिदानींसदानींसदानीरा ७७ चंडिदरचपलचोलव्यक्तोरुविलोकनैकर
सिकेन धूलिरपादपिनमयाचरणाहतोक्तंचितंचक्षुः ७८ चलकुंडलचलदलकस्ख
लदुरसिजवसनसक्तहृदयुगं जघनमरुक्रमकूणितनयनमिदंहरतिगतमस्याः ७९
चरणौःपराणसेकतमफलमिदंलिखसिमधुपकेतक्याः इहवसतिकांतिसारेनांतःस
लिलापिमधुसिंधुः ८० चिरकालपथिकशंकातरंगितास्ःकिमीक्षसेमुग्ध चलितं

गो० ग्रा० ग्राश्लेषव्रणराजीयमेतस्याः ८१ चपलांयथामदांधस्छायामप्यात्मनःकरीहंति आस्फा
१७ लयतिकरंप्रतिगजमत्तथायंपुरोरुद्धः ८२ चुंबनलोलुपमरुधरहृतकाश्मीरंस्मरल्लनृष्या
मि हृदयमिदंदाजानस्तंमंतस्यास्तरूयुग ८३ चिकुरविवारणतिर्यग्गातकंठीविमु
खवृत्तिरपिबाला चामियमंगुलिकल्पितकचावकाशाविलोकयति ८४ चुंबनहृतांजना
ईस्फुटजागररागमीलन्नयनांह्रिपमि किमुपसिवियोगकातरमसमेपुरिवार्द्धनाराचे ८५ छा
याग्राहीचंद्रःकूटचंमततमंबुजंव्रजति हिचोमयंसमायांसौतितवैवाननंलोकः ८६ छा
यामात्रंपत्रयन्नधोमुखोमुकुंतनधैर्येण तुदतिममहृदयमिषुणाराधावक्रंकिरीटीव ८७
जलबिंदवःकतिपयेनयनात्कमनोज्ञमेतवस्खलिताः कांतेममगंतव्यानूरैतेरेवयिच्छिलि। रामः०
ता ८८ जृंभोत्तंभितदोर्युगयंत्रिततांटकपीडितकपोलं तस्याःस्मरामिजल्पकरणाकुलि १७
तांजनमलसदृष्टिमुखे ८९ जागरयिचापुरुषंपरंवनेसर्वतोमुखंहरसि अपिन्नारदनु

रूपंतवन्नीलमिदंजातिग्रालिन्याः ९० जीवामिलंघितावधिदिनेतिलज्जावशोनगेहिन्या
।।मयिनिकृतोपिबाष्पैरसवर्णैर्व्यंजितोमानः ९१ जाल्मोगुरुःसुधृष्टोवामेतरचरणभेदउप
देष्टाः ख्यातिर्गुणधवलइतित्वमसिसुखंदृषनरथ्यास ९२ कूरवीतौषधिबाधस्तिष्टमुखंदन्त
संगमखिलंते असुलभलोकाकर्षणपाषाणसखेनमोस्तुसिमां ९३ जीवनहेतोर्मिलिता
मुंचतिकरकर्षणेननखलुचां नौरिवनिम्नसुंदरमुग्धातद्विरसतोमागाः ९४ जघनेनचाप
लंतववितनुतेयंतनूरुतापितनुः न्नाणेनेवक्षीणास्मरासिपुत्रीमनोविघ्नाति ९५ ज्योत्स्ना
मिसारससुवितवेत्रोव्याकोशमल्लिकोत्तंसे विन्नासिमनोनिघ्नितेवस्मरस्यकुमुदसरुद्धु
रिका ९६ जडसुषयसिपरतरुणीग्रहिणीकारयसिकेवलंसेवां आलिंगतिदिग्गाभिंदुःसा
नुन्नीलांबारिवीहयति ९७ ज्योत्स्नागर्भितसैकतमध्यगतःस्फुरतियामुनःपूरः दुग्धनि
धौनागाधिपतल्पतल्पेसुप्तइवकृष्णः ९८ इतिजकारव्रज्या ३कतकंकणपाणिन्हैपे

गो॰स्रा॰ संभावलंबनैर्मौनैः श्रोत्रयसिश्रुकरुदितैरपि मुंदरि मंदिरद्वारं ९९ ढक्कामाहत्य मदं वित
१९ न्वतेकरिणाइव चिरं पुरुषः स्त्रीणां करिणीनामिव मदः पुनः स्वकुलनाशाया ३०० तांता
पयंति मन्मथबाणास्त्वां ग्रीणायं मिनेसुभगतपनकरास्नपनशिलां धालयंति विधुं मधुस्यंति
॥१ तवसुतनुसानुमत्या बद्धभ्रातुजनितनितंबरागायाः गिरिवरभुव इवजाम्नेनाम्लानि
ध्युयुजेनद्विं २ त्यक्तो मुंचति जीवति जीवनमुज्झति नानुयहेपि जोलचं किंप्रारुपेव यस्माक
रस्य करणीयमस्य मया ३ यद्विरहापदि पांडुस्तनं गीच्छायये वकेवलया हंसीवयोस्त्रा
यासा सुभगधत्यभिज्ञेया ४ यपि विनिवेश्यितचित्रा सुभगगना केवलेन कायेन घनजा
लरुद्धमीनानदीवसावीरमात्रेण ५ यपि संसक्तं तस्याः कठोरतरहृदयमसमन्त्रारतरलं राम॰
।मारुतचलमंचलमिव कंटकसंपर्कतः स्फुटितं ६ यमसूर्यंपश्यामलिपदमपि न विनाप १९
वारणं वमसि छायेकिमिह विधेयं मुंचंति न मूर्त्तिमंतस्त्वां ७ तवविरहे विस्तारितरजनौजनि

तें चंदनलेपे बिसिनीवमाघमासेवि बाकृताशेन मारब्धा ८ तरुणि चचरणाहतिकुसु
मितकंकेलिकोरकप्रकरं कुटिलचरितासपत्नीन पिबति वतशोकविकलापि ९ तत्त्वे
ष्पसुरिवगुरुखिमनसिजसमरेश्रमेणु जिष्णेव गेहेश्रीरिवगुरुजनपुरतो मूर्त्तेवसाव्रीडा १०
यमलन्यामम तावन्मोक्तुमशाकस्य सन्मुखं व्रजतः छायेवापसरंती निस्यानन्निवार्यसैया
वत् ११ तपसाल्केनितराष श्रोटवलो नखलु फाल्गुनेप्यासीत् मधुनाश्रमत्तमधुनाकोम
लं मिहिरमिवसहते १२ वरुमनदिवसगणनावलरुरेषाभिरंकिता सुभग गंडस्थली
वस्याः पांडुरितामवननित्तिरिव १३ तस्यायाम्यस्याहंसखिवक्रस्निग्धमधुरस्याहृद्या॥
विषात देकनैयापोत्रिणाखदंष्ट्रयाधरणी १४ यपिकुत्यामवटकमवैश्रवणोवसतु वसतुवा
लक्ष्मीः पामरकुगारपाताका सरसिरसैवतेरक्ता १५ तवमुखरवदनदोषंसहमानामो
कुमकुमास्तुतनुः सावहति विटजनवंतं घुणामंतः शालनं जीव १६ नृणामुखमपिनखलु

चांत्यजेत्यमी हरिणवैरिणः शबराः यत्रासैव जीवितमिदं त्यजयोजितशृंगसंग्रामः १७
त्रिपुररिपोरिव गंगामममानिनिजनितमदनदाहस्य जीवनमर्पितशिरसोदद्रासि चिक
रग्रहेणैव १८ चक्रकथासुमुखराः सनिंदसानंदसा बहिस्थ इव मखचुसखीनां पुरतस्त
याकृतार्थीकृतस्सुभगः १९ चयिसर्प्पति पथि दृष्टिः सुंदर वृतिविवरनिर्गतातस्याः दरतर
लनितंबो वलजालात्राफरीवविस्फुरति २० तेसुतनुशून्यहृदयायेत्रांषं शून्यहृदयमनि
दयति अंगीकृतकरपत्रोयस्तवहस्तयलंकुरुषे २१ तेऽत्रोष्टिनः कसंप्रतिशाकध्वजयेऽकं
तस्तवोच्छ्रायः ईर्ष्यां वामेर्दैवाद्युनातनास्त्रां विधित्संति २२ तानवमेत्सच्छिन्नः परोपहिता
रागमदनसंघटितः कर्णइव कामिनीनां न राजते निर्भरः प्रेमा २३ तस्मिन्नगताग्रेनाबेवि
गतरसे शुंविनाकल्पइवपुरुषे अपिमूर्तिनाजिमसिनेनागरत्राह्योविडंबाय २४ तमसिघने
विषमे पथि जंबुकमुल्कासुस्वं प्रपन्नास्म किंकुर्मः सोपिसरैवस्थितोमुखंमुद्रयिचैव २५ चा

मनिजपतोमानिनिममगरिमगुणोपिदोषतां यातः यं किलकृत्वां तटिनीपिपासतः सिं
धुरस्येव २६ तिमिरेपिहृदकृपाकमिनाश्लेषेचरहसि मुखराच शंषमयवजयराजी
हपतिशिरसा सहस्फुटतु २७ नववृत्तेनगुणेनचसमुचितसंपन्नां कंबलुवनायाः
हारस्त्रजइवसुंदरिकृतः पुननायिकस्तरलः २८ इतितकारवज्ज्या दत्तनिबिनीत
मानागृहिणीहर्षोल्लसकपोलतटं चुंबननिषेधमिषतोवदनं पिदधातिपाणिभ्यां २
९ देहस्तंभस्खलनं शैथिल्यं वेपथुः श्रीयध्यानं पथिपथि गगनाश्लेषः कामिनिकस्तो
निसारगुणः ३० वापयतादिवसानिचदीयविरहेणतीव्रतापेन ग्रीष्मेणेव नलिन्या
जीवनमल्पीकृतं तस्याः ३१ दुर्जनसहवासादपिशीलोत्कर्षं न सज्जनस्त्यजति वृति
पर्वतपनवासीनिःसृतमात्रः शशांशीतः ३२ दयितप्रहितां दूतीमालंब्य करेणतम
सिगच्छंती स्वेदच्युतमृगनाभिर्हराभोरांगिहत्रयासि ३३ दयितागुणाः प्रकाशं नीतः सखै

ववदनदोषण प्रतिदिनविदलितवाटीवृतिग्रदैन्यैः खिद्यसे कीमिति ३४ दाक्षिण्यान्मदिमा
नंदधतं मानानुमेनमचमंस्थाः रौद्रीमुपागतेस्मिन् कः स्मरते दृष्टिमपि दातुं ३५ दृष्टैव
विरहकातरतारकया प्रियमुखे समर्पितया यांति मृगवल्लभायाः कुलिंदबाणार्दिताः प्रा
णाः ३६ दूरस्थापितहृदयो गूढरहस्यो निकामसान्द्रोकः आश्लेषो बालानां भवति ख
लानांच संभेदः ३७ द्वारेगुरवः कोणेश्वश्रुकः स कान्तो निशि शून्यगृहे सख्यः कालासहहृम
लाप्रियप्रसीद प्रयातमहः ३८ दधिकणमुक्तानरणश्वासोत्तुंगस्तनार्पणा मनोज्ञं प्रि
यमालिंगति गोपी मंथश्रमसंथरैरंगैः ३९ दलितोद्वेगेन सखि प्रियेत्वल्लग्नेन रागमावह
ता मोहयता नायनीयतां बूलेनेव नीतास्मि ४० दृष्टमदृष्टप्रायं दयितं रूचाप्रका
शितस्तनया हृदये करेण ताडितमथ मिथ्यालज्जितत्रपया ४१ दर्शितयमुनोच्छ्राये
क्षुविल्लमन्नाजिनलतितवनयने क्षिप्रहलेहजधरइव पुरमेवावर्जितं सुतनु ४२ द

यितप्रार्थितदुर्लभमुखमदिरासारसेकसुकुमारः व्यथयति विरहे वकुलः घकपरिचयः प्र
तिकविनाना ४३ द्वित्रैरेष्यामि दिनैरिति किं तव वचसि सखि न वाश्वासः कथयति चिरप
थिकं तं दूरनिषीतोनखांकस्ते ४४ दयितस्य चोन्मीलितपमंजलस्खलितचरणनखा
लाक्षे गर्वभरमुषेरिते साखितविक्रान्किमपराधयसि ४५ दुष्ट्यहेणगेहिनि तेन कु
पुत्रेण किं प्रजातेन यो मे मेवनिजं कुलमंगारकवत्कृतं येन ४६ दर्शिततापोच्छ्राये स्ते
जावद्भिः सुगोत्रसंजातैः हीरैरप्यपि वीरैरापत्स्वपि गम्यते नाथः ४७ दरनिद्राणस्या
पि स्मरस्पर्शिम्येन निर्गता शून्यं मुग्धे तव दृढिरसा वर्जुनयंत्रे पुरि वहंति ४८ दुर्गतगृ
हिणी तनये करुणार्द्रा प्रियतमे च रागमयी मुग्धा रता नियोगेन मन्यते न प्रतिक्षिपति
४९ दुर्गतगेहिनि जर्जरमंदिरसुप्तैर्भवद्भिः सचंद्र वयमिंदुवंचितदृशो निचुलितदो
नाविहारिण्यः ५० दीपदशाकुलयुवतिर्वैदग्ध्येनैव मार्जिनतामेति दोषाक्षपिमृ

गो० आ० षायै गणिकायाः शालिकलायाश्च ५१ दीर्घगवाक्षमुखांतर्निपातिनस्तरणिरश्मयः शो
२१ णाः नृहरिनखाङ्कदानवचक्षुः प्रविशंति सौधतलं ५२ दुष्टसखीसहितेयं पूर्णेंदुमु
खीसुखायनेदानीं राकेवविष्टियुक्ताभवतो निमताय निद्रामवतु ५३ दलितपला
लपुंजे वृषभं परिभवति गृहपतौ कुपिते निभृतनिमीलितविघ्नो हालिकवधूदेवरोहस
तः ५४ दरतरलेक्षतिमिरक्षसितदरोन्नतैतवमुखेचदरहसिते आस्तांकुसुमंवीरः
स्मरोधुनाविजयतु धनुषापि ५५ दीप्यंतां येदीप्तेघटीतामरायश्चवीरपुरुषाश्च तेजःस्व
विनाशायतुनृणां नृणानामिवजम्बूनां ५६ इतिदकारव्रज्या धूमैरश्रुनिपात
यदहनिशावयादहनमलिनयांगारैः जागरयिष्यतिदुर्गतगृहिणीचांतदपि शिशिरनि राम०
शा ५७ धैर्यंनिधेहिगच्छतुरजनी सोप्यस्तु सुमुखि सोकंठः प्रविशाहृदीतस्यहरदहना २१
धूतधुक्षस्मरेषुरिव ५८ धवलनखलक्ष्मदुर्बलमकलितनेपथ्यमकपिहितात्स्याः।

ङ्गसामिमदवलोकत्रिगुणाङ्कवपुःपुरधारि ५९ धूमरिंगेप्यसतां पराहिंसैवप्रयोजिकाभ
वति काकानामग्निषेके कारणतामरवृष्टिरनुभवति ६० इतिधकारव्रज्या नीरावत
रणादेतुरसैकतसंभेदमेदुरैः शिशिरे सज्जतिन्तूलरात्रौ स्थूलपटैरपिवैतः सरितः ।।
६१ निजकायछायायांविश्रम्यनिदाघविपदमपनेतुं बनविविधासनुगामुग्धकुर
गीयमाचरति ६२ नहसंतिजरवइतियदलचवनितानमंतिनंदमपि सखिसयत्नो
दात्तनयोनित्यं कंदलितकंदर्पः ६३ नीतास्वभावमर्पितवपुरपिवाम्यनकामिनीत्य
जति हरदेहार्धग्रथितानिदर्शनिपार्वतीतत्र ६४ नागरगोणानुमितस्ववधूसौंदर्यगर्व
तरलस्य निपततिपदंनभूमौ ग्रामतिपुरतंतुवायस्य ६५ निपतति चरणेकोणप्रक्षि
निशायतिरीत्सतेकस्तत सखिसखलुलोकपुरतःखलःस्वगरिमाणमुफिरति ६६ नवी
नोचयितुंकाकाः स्मांमहान्मोचितायदि कथं वित मंदरगिरिरिवगरलंनिवर्तितेनर्थमुक्ता

स्म ६७ नियतैः कपर्दैर्निषेव्यं स्खलितेन तथा विहंसमाश्रयति संज्ञवदन्यगतिः कः सं
क्रमकाष्ठदुरीन्नांच ६८ निजपदगतिगुणारं निगतां करिणामक्कवीनांच वहतामपि
महिमानं त्रोणाये सुकनाराव ६९ नोन्नपरैतेन स्नेहं हरति न निर्वाति नमलिनं वमति
ातस्योष्कृत्तो निर्मितानिर्मितप्रेमा स्वप्रदीपइव ७० निहितान्निहितानुकृति नियतं मम
पार्थिवानपि प्रेम ग्रामंग्रामं तिष्ठति तत्रैव कुलालचक्रमिवा ७१ निर्नरमपि संमु
कं दृष्ट्वा प्रातः पिबन्न तृप्यामि जघनमनंगुकमस्याः कोकइवाग्निर्मिरकरबिंबं ७२
निविडुघटितोरुयुगलां श्वासोन्नव्यस्तनापि निव्यजनां तां स्निग्धकल्पितदृष्टिस्मरा।
मिरतनिः सहांसुतनुं ७३ निर्गुणाइतिमृतइतिचवावेकार्थानिधायिनो विद्धि पन्नय
धनुर्गुणा सूत्र्यं निर्जीवयदि हिन्नांसति ७४ निजसूक्ष्मसूत्रजीवी विलोचनं तरुणातो।
रूणाहरतु स्वयमुद्गृहीतबडिशाः कर्कटइव मर्कटः स्फुरतः ७५ नागरगीतिरिवा

सौयामक्षित्यापिन्नृपितासुतनुः कस्तूरीनमृगोदरवासवशाद्विस्त्वतामेति ७६ नख
लिखितस्तनितक्रुरबकमयवक्ष्टमूमिलुलिनविरसांगि हृत्यविदारणानिः सृतकु
सुमास्त्वत्रखेहरसिमनः ७७ नीताल्पमिमान मियं तस्यां गिरिमाणमधिकमाधिष्णयुमि
ामारइवविषमजार्यः घुट्टुर्वहोन्नवति गृहवासः ७८ नचहूती नचयांच्यानवांजालि
नचांजकयन्तुविक्षेपः सौभाग्यमानिनासाखिकचग्रहः प्रथममम न्नियोगः ७९ निन्नि
विषमकुसुमविशिखप्रेरितयोर्मौनिलब्धरतिरसयोः मान — थैवविलसन्तिद्यप्रयोइ
शिथिलग्रंथिः ८० निजगात्रनिर्विशेषस्यापितमपिसारमखिलमादाय निर्मोकं
चतिपुरुषंचवारवधूः ८१ रुत्सश्रमघर्माद्रमुंचमिरुच्छ्रेलकंचुकंसुतनुः मकरंदोदय
नुष्ठंमदनधनुर्वल्लिखिचोलं ८२ नाहंवदामिसुतनुत्वमजालापचंडचरितावां प्रेम
स्वभावमुल्लत्नयमुदयतिममतुहृदयस्य ८३ नखदशनमुष्टिपातैरदयैरालिंग

गो॰ स्वा॰ नैश्चसुनगम्य अपराधं त्वं सत्यः क्षांतिं रचयंति रागिण्यः ८४ न निरूपितोसि सख्या
नियतं नत्रत्रिभागमात्रेण हारयति येन कुसुमं विमुखेन त्यक्तं इव ८५ न गु
२३ णेन लक्ष्मणेपि च न यसि च रूपेण चनादरो विहितः त्वमपि सोरमेयिघंटा कपिलापु
त्रीति बद्धेयं ८६ निःकारणायरायं निःकारणकलहरोषपरितोषं सामान्यमरणा
जीवनसुखदुःखं जयति दांपत्यं ८७ न ग्राम्यसे करांभोरुहृदयाल्लापिपिवितनुधवा
धांतं मम मग्ना वल्लितकुसुमायुधविशिखफलिकेव ८८ नाथेति परुषमुचितं त्रिये
ति दासेति स्वनुपहोयत्र तद्दांपत्यमतोन्मी नारी रज्जुपशुपुरुषः ८९ निहिताया
मस्यामपि सैवं कामनसि मेस्फुरति रेखानरोपधानात् पत्राङ्करसाराजि रिवदयिता राम॰
९० निधिनिरूपस्थानस्योपरि चिह्नार्थमिवद्धता निहिता लोमयातिततनूदरि जघन २३
तटाउपरि रोमाली ९१ निहिताक्षिलोचनाया स्वंतस्याहरसि हृदयपर्यंतोनमुन

गसमुपचितमीदृग्मामंगुलिदानेभुजंगिलसि ९२ नीतागारे रजनीजागरमकं चस
दरं दत्वा अचिरेणाकैनन रूणौदुग्धापित्रीवमस्कासि ९३ नन्दत्रेमा विंदाबुदरेकन्
के मणेर्दृशामसुज्ञो यत्रवस्तुनेजस्तदखिलमोजापितमज्ञमित्रस्य ९४ न सवर्णो
न च रूपं न सत्क्रियाकापि न कृठतिः बालातद्विरहापद्दिजानाप्लनंत्रानाषेव ९५
न विभूषणेन वास्त्रावप्रगुणा नैवजयासि सखियूनः अवधीरिता स्वचास्त्राकुसुम
शार्मल्लविघेना ९६ नेत्राब्ज्लोम्यामंत्राम प्रेयान्यथाथथ्यास्ति नथा सखिमथ
तिमनोर्ममदविधिनांडंमयद्दंड्डव ९७ नाना वर्णाकुरूपं प्रकल्पयंति मनोहरतनं
चित्रकूरत्नाजि केवनांसा पति भिन्निनावयति ९८ इति नकारक्ष्यः पथिकास
क्ता किंचिन्न वेदधनकल्मम गोपिता गोपी केलिकलाङ्कं कारैः कीरावलिमोघमप
सरसि ९९ प्रणामति पत्यतिचुंबति संश्लिष्यति पुलकमुकुलितैरंगैः प्रियसंगाय

स्फुरितांवियोगिनीवामबाहुलतां ४०० अविनयपिसुनचनिर्गंतुंजानामिव्याकुलच
मानतुषे बालकचेतसितस्याश्चक्रव्यूहेभिमन्युरिव १ पत्युपानुरूपमिंदिंदिरेणामाकंद
गोषरोमुर्षेरः अपिचपिचुमंदमुकुलेमौकुलिकुलमाकुलंमिलति २ प्रतिबिंबसंभृतान
नमादर्शंसुमुखिममसखीहस्तात् आदातुमिच्छसिमुधाकिंलीलाकमलमोहेनी ३
प्राचीनाचलमौलेर्यथारागीगनमध्यमधिवसति चांसखिपश्यामितथाछायामिवसं
कुचन्मातां प्रांगणकोणोपिनिशापतिःसंतापंसुधामयोहरति यस्मिंराजनिकूरइवस
खिननिरुणद्धिगेहपतिः ४ पतिपुलकदंतगात्रीस्वछायांवीक्ष्यापियासनया अभिसर
तिसुभगसाचांविदलंतीकंटकंतमसि ५ प्रतिचूःश्नूको विपक्षेदंडःशृंगारसंकथागुरुषु
।पुरुषायितंपराप्त्ला बालेपरिभाव्यतांहाय: ६ परमोहनायमुक्तोनिःकरुणेतरुणी
नवकटाक्षोयं विनिघ्नेषइवकलितकर्णःप्रविशतिहृदयंननिःसरति ७ अपदालंबिता

नमिश्रुंबंतीप्रीतिमीतमिथुराद्वौ प्रावारायनिवेश्यितचिबुकतयानपतितासुतनुः ८
प्रातरुपागत्यमृषावदतःसखिनास्याविघनेव्रीडा मुखलग्नयापियोयंनलज्जतेदग्धकाल
कया ९ प्रत्योत्तरस्तनुर्दरिफाल्गुनमासाद्यनिर्जितविपक्षः वैराटिरिवपतंगःप्रत्यान
यनंकरोतिगवां १० प्रमदवनंतवचस्तनशैलंमूलंगभीरसरसांच जगतिनिदाघनिरस्तं
त्रैलोक्यंदुर्गत्रयंश्रयति ११ वांछतितवापराधंमानंमर्दयितिनिर्वृतिहरति स्वकृतान्निहं
तिनापथान्जागरदीर्घानिद्रासुभग १२ प्रियआयातेदूरादद्भुतइवसंगमोनवस्पूर्वः॥
मानरुदितप्रसादाःपुनरासन्नपरसुरतादौ १३ पूर्वमहीधरनिर्गोषैरेतमःसमासन्नामिहिरक
रकलिते शूलप्रोतंसरुधिरमिदंमंधकरपुरिवाभाति १४ परिहृतनानिस्तुमत्रिवलिग्रप
मस्तनाग्रमलसांक्षि वकुधवलजघनरेषंवपुर्नपुरुषायितसहंते १५ आरब्धनिधुवनैव
स्वेदजलंकोमलांगिकिंवहसि ज्यामर्पयितुंनमिताकुसुमास्त्रधनुर्लतेवमधु १६ पुंसां

दर्शयसुंदरिमुखेंदुमीषत्त्रपामपाकृत्य जायाजितइतिरूढाजनश्रुतिर्मय्यमोनवतु १७।
प्रसरतुशरत्त्रियामाजगंतिधवलयतुधामतुहिनांशोः पंजरचकोरिकाणांकणिकाक
ल्पोपिनविशेषः १८ पतितंसुकेस्तनार्पितहस्तांतांनिविडजघनपिहितोरुं रदपदवि
गलितफूत्कृतिशतधुनदीपांमनःस्मरति १९ प्रथमागतिसोकंगविरचलितेयंविजृंभ्रो
षेण वक्षोतिसांगरागाःप्रथितरवस्तवसमाधानं २० परितःस्फुरितमहौषधिमणि
निकरेकेलीतल्पइववरोले कांचीगुणाइवपतिताःस्थितेकरुलःफणीस्फुरति २१ शारू
पिशैलश्रेणीनितंबमुक्तनूद्दिगंतरेत्त्वमसि चपलोंतरघनकिंतववचनीयंपवनवत्पोसि
२२ प्रतिदिवसक्षीणदशास्तवैषवसनांचलोतिकरकृष्टः निजनायकमतिकृपणंकथ। राम०
यतिकृत्यामस्ववविरलः २३ पथिककथंचपलोत्कुलमंबुदजलबिंदुनिवहमाविषस्यं॥ २५
मयपुरकनकप्रवाप्रिवाशिवशारम्त्रिपिनाविर्तसहसे २४ पथिकंश्रमेणसुसंदरतरला

तरुणिसुमधुरछाया आलंबमानवेणीसुषयसित्राखेवसारोहा २५ प्रददातिनापरासां
प्रवेशमपिपीनतुंगजघनोरूः याशुमकीलनावयानाहृदिबहिरहमपापि ४२६ पातनि
पातियथायथात्मजालुलिलितनिःसहैरंगैः जामातरिमुदितमनास्तथातथासादराश्वश्रू
: २७ प्रणयचलितोपिसकपटकोपकटाक्षैर्मयाहृतस्तेमनः त्रासतरलोगृहीतःसहासमर
नसंप्रियःकंठे २८ प्रियदुर्नयेनहृदयस्फुटसियदिस्फुटनमपितवक्षाध्यं तत्केलिसमर
तल्पीकृतस्यवसनांचलस्येव २९ पवनोपनीतसौरभदूरोत्कपूरपम्मिनीलुब्धः अप
रीकृतस्वपक्षोगंताहंतापदंमधुपः ३० प्रेमलघूकृतकेशववक्षोभरविपुलपुलकक
वकलन्या गोवर्धनगिरिगुरुतांमुग्धवधूर्निभृतमुपहसति ३१ प्रियविरहनिःसहाया
:सहजविपक्षाभिरपिसपत्नीभिः रक्ष्यतेहरिणाक्ष्याः प्राणागृहभंगभीताभिः ३२ प्रकट
यतिरागमधिकंजल्पनमिदंवक्रिमाणमावहति क्षीणायतिप्रतिपदंहृतिस्मुकस्येवदयितस्य

गो०आ० ३३ प्रविशंत्याः प्रियहृदयं बालायाः प्रबलयौवनव्याप्तं नवनिर्मितदरतरंगितनयन
२६ मयेनासिनापंथाः ३४ घृणयापराधरोषप्रसादविश्वासकेलिपांडित्यैः रूढः प्रेमाद्रि
यते किमु बालाकुतुकमात्रेण ३५ पूर्वैरविविक्तैश्चरितैर्नवोपि पूज्यतां नवतः मुंच
मदमस्यगंधाप्युवत्तिर्गजगंजनीयोसि ३६ प्रसभं प्रवेशिता मामावासागारं कथंचन सखी
भिः नश्यणोनी विभ्रान्तः सा निर्गमनस्य संकेतं ३७ पूजाविना प्रतिष्ठां नास्ति न मंत्रं विना प्र
तिष्ठा च तदुभयविप्रतिपन्नः पतन्पातु गीर्वाणपाषाणं ३८ पूर्वाधिको गृहिण्यां बद्धमा
नः प्रेमनर्मविश्वासः गौरधिकेयं कथयति रागं बालाविभक्तमिव ३९ पुलकितकगोरपीव
रकुचकलशाश्लेषवेदनाखिन्नः नांगोरुपवीतफणीवांछति मानग्रहं देव्याः ४० प्रियसंगा राम०
यातो हराविनियामति विभ्रुवगेहिन्याः पथिकेभ्यः पूर्वागतशंतिगवाक्षापि न्यातनिरीक्षरा ४१ २६
दृष्टं प्रयच्छमास्मत्राहरादपसर्पविहितवैमुख्य वामनिधावति न रुणस्ति दपिगुणाकर्षं तरजेयं ४२

प्रियया कुंकुमपिंजरपाणिद्वययोजनं किं तं वासः प्रहितं मां याज्ञां जलिसहस्रकरणाय मि
ह्यति ४३ प्रावारांतरितेयं प्रियस्य वदने धरं समर्पयति प्राग्गिरिपिहितारात्रिः संध्यारा
गिनस्येव ४४ परपतिनिर्दयकुलटात्रोषितग्रामनेर्ष्यानकोपेन दग्धमम तोयत प्रारोदि
मित वतानवं वीक्ष्य ४५ प्रांगणएवकदामां क्षिप्यंती मत्युकंपि कुचकलशा अंसनिषण्ण
मुखी सास्त्रपयति बाष्पेणाममहृदयं ४६ धौतैः प्रत्यास्तसचासाश्रु हकेवीक्षितासबलश्वासैः॥
बुवति मृतस्य वदनं मृतमुखालोकेक्षितं बाला ४७ पिशुनः खलु सुजनानां खलमेव पुरो विधाय
सितव्यः कृत्वा क्रूरमात्मीयं जिगाय बाणं रणे विष्णुः ४८ पिबमधुपवकुलकलिकां हरेरस
साग्रमाधाय अधरदलिपसमाप्ये मधुनि मुधावदनमर्पयसि ४९ प्रायेणैव हि मलिना
मलिनानामाश्रयच महंति कालिंदीपुरभेदः कालियपुष्टे भेदं न वति ५० पत्रेषु प्रियतनु
विघनटनमयेनश्रान्तिमौलिदेह संजग्ना सुभगे कैदैवतमुमाश्रितरसा भागीरथी वहति ५१

पथिकवधूजनलोचनबाष्पनदीमातृकप्रदेशेषु घनमंडलमाखंडलधनुषाकुंडलितमिव
विधिना ५२ प्रतिवेशिमित्रबंधुसुहृदाकुल्यागतोपि गेहिन्या अतिकेलिलंपटतया दिन
मेकमगोपि गेहपतिः ५३ परपटवस्त्रजकीमिर्मलिनोमुक्तापि निर्दयं ताभिः अर्थय
हेतोनविनाजयन्मुक्तोसिकुलटाभिः ५४ इतिपकारव्रज्या बकुयोषितिलाक्षा
णात्रिरात्रिवयस्येन दयितउपहसिते नकालकलितलज्जापिशुनयतिसखीषुसौभाग्यं ॥
५५ बंधनभाजोमुष्याश्चिकुरकलापस्यमुक्तमानस्य सिंदूरितसीमंतछलेनहृदयं विदी
र्णमिव ५६ बलमपिवसतिमयीतिश्रेष्ठानिगुरुगर्वरूढं वदति नज्ञायया जनानां मुर्षेमी
ह्निनमावृतस्मितया ५७ बलवदनिलोपनीतस्फुटितनवांभोजसौरभोमधुपः भ्रांत्यभ्य
तेनजिह्मानासानिक्षिप्तरज्जुरिव ५८ बाणां हरिरिव कुरुते सुजनो बहुदोषमप्यदोषमेव
॥ यावद्दोषं जायतेमलिम्लुचाश्वश्वःपुनःपिशुनाः ५९ बौद्धस्येवक्षणिकोयद्यपि बहुवस्त्र

नस्यतवभावः नम्रान्नम्रानृरिवनतुतस्याविघटतेमैत्री ६० इतिबकारः भ्रमसिप्र
कटयसिरदंकरं प्रसारयसि तृणमपिश्रयसि धिङ्मानं तवकुंजरजीवं नजुहोषि जठराग्नौ ॥
६१ भूतिमयं कुरुते भिक्षूणामपि संलग्नमेनमपि भुजनः सेवसुवर्णादिस्थाने त्वांके गरिमाप
राधेन ६२ भवतिनिदाघेदीर्घयथेहयमुनेवयामिनीतन्वी दीपाश्ववदिवसाश्चापि तथा
क्रमेणपृथ्वीपांसः ६३ भवतामहतिस्नेहानलेपिता पथिकहेमगुटिकेव तन्वीहस्तेनापि
स्पृष्टुमशक्यैर्नसासह्या ६४ भूमिलुलितैककुंडलमुत्तंभितकांडपटमियं मुग्धा पश्यंतीनि
श्वासैः क्षिपति मनोरेणुपूरमपि ६५ भवांतालिंगितिभुजंगीजातः किलभोगिचक्रवर्तीत्वं कं
चुकवनेचरीस्तनमभिलषतःस्फुरतिलघिमाते ६६ नैसभुजापल्लीपतिरितिसुतस्तवधूस
दृष्टनो। रक्ष्कजयमियदेकःशून्येषुरमदसिसुखमस्मि ६७ भोगाद्भ्रमस्सरस्तांहृदज्जातेकं
र्तोनत्निमुखस्य हृदयप्रमदापि श्रीरपिभृत्यस्यभोगाय ६८ भवितासिरजनिपस्याम

ध्वस्रमृत्रांतयेपदंदधती सबलावलयितजंघाबंधांमामुरसिपातयति ६९ मूषणतांगज
तःसखिकषणाविशुद्धस्यजातरूपस्य पुरुषस्यचकनकस्यचयुक्तोगरिमासरागस्य ७०
नस्मपरुषेपिगिरिस्नेहमयीचमुचितेनमुखगासि मोघस्तुयिजनबादोसदोषधिप्रस्तु
हितेति ७१ मयापिहितंबालायाःपीवरमूरुद्वयंस्मरोन्क्रिः निद्रायांप्रेमार्द्रःपत्युपतिनिश्व
स्यनिश्वस्य ७२ भ्रमरीवकोशगर्भेगंधहृताकुसुममनुसरंतीचां अव्यक्तंकूजंतीशंके
घनतमसिसान्त्रमति ७३ ग्रामंग्रामंस्थितयास्नेहेतवपयसितत्रतत्रैव आवर्त्तपतितनौ
कायितमनयाविनयमपनी ७४ भ्रमयसिगुणाम्मयिकंवग्रहयोग्यानालमंदिरोपांते हालि
कनंदीनितरुणाक्कुप्तिनोमेहिरजुरिव ७५ नालनयनेग्निरिपुर्मौलौगंगाभुजंगमणि
दीपाः तदपितमोमयएवचर्मांशाकः क्रूरतिमतिरोषे ७६ मधुमदवीतत्राडायथायथा
लपतिसंमुखैबाला तन्मुषमजातन्नृपिस्तथातथावल्लमःपिबति ७७ मित्रैरालोच्यसमं

गुरुरुचावदनमपिसमारध्यः।।अर्थःमतामिवहतोमुखवैलक्ष्येगमानोयं ७८ ममरागिणो
मनस्विनिकरमर्पयतोदद्यासिद्दष्टमपि यदिनदपिकमलबंधोरिवमन्येस्वस्यसौभाग्यं ७९
मास्मृत्रामामितिसकुपितिमिवमाणितंव्यंजितानवव्रीडा आलिंगितयासस्मितमुक्तमनाच
रकिंकुरुषे ८० मूलविचनिचुलानांहृदयानिचकूलवसतिकुलटानां मुदिरसदिराप्रमत्त
गोदावरिकिविदारयसि ८१ मलयक्रमसाराणामिवधीराणांगुणाप्रकर्षोपि जडसम
यनिपतितानामनादरायैवनगुणाय ८२ मधुमथनमौलिमालेसखितुलयसितुलसिकं
मुधाराधां यन्नवपदमदसीयंसुरभयितुंसौरभोद्भेदः ८३ सयियास्यतिरुचावधीदिनसं
ख्यांचुंबनंतथाश्लेष प्रिययानुरागवितासाताावसुरताकुमारजानी ८४ मृगमदनिदान
मद्दर्वीकुंकुममपिफलवादिकावमति हृदविलासिनिभवतीपुरमेकापोरसर्वस्वं ८५ मधु
दिवसेषुभ्राम्मन्यथायथाविभ्रातिमानसंभ्रमरः सखिलोहकटकनिभस्तथातथामदनवा

गा०स्रा०
२९

न्निषोपि ८६ मपिचलितेनवमुक्ता दन्ताः सुताराः प्रियेसपानीयाः सत्यममूल्याः सद्यः प्र
यांतिममहृदपहारवं ८७ मुग्धेममनसिन्नाराः स्मरस्यपंचापिसतत्तंलग्नाः न्नांकेस्तन
गुटिकाद्वयमर्पितमेतेनतवहृदये ८८ मधुमथनवदनविनिहितवंशीछिद्रानुसारिणो
रागाः हंतहरंतिमनोममनालिकाविनिःश्वासाःस्मरस्येव ८९ महतोःसुवृत्तयोःसखिहृदयग्र
हंतोःसुवृत्तयोः सा खेयोग्यायोःसमुच्छ्रितयोः सज्जनयोःस्तनयोरपिनिरंतरंसंगतंभवति ९०
मुग्धमपिमन्यमानागुणिनमपिसकरगतंपिशुनाः जीवाकर्षेणविनाधनुरिवयोधानमुंचंति॥
९१ ममवारितस्यवक्त्रान्निर्यातोभूयःस्वयंचमावयतः जातोद्वित्रीवतस्यांनसखेविनिवर्तते
मोहः ९२ मग्नोसिनर्मदायारसेहृतोवीचिविलोचनक्षेपैः यद्धसेअसेतरुवरनृशंसोपि
निस्राघ्यः ९३ मेनामुल्लासयतिस्मेरयतिहरिंगिरिंचविमुखयति कृतकरबंधविलंबःपरिण
यनेगिरिशाकरपंकंपः ९४ मधुगंधिघर्मताम्रत्रिवलिकमखर्वजुक्तिघूर्णदरुणाक्षं तस्याः

राम०
२९

कदाधरामृतमाननमवधूयपास्यामि ९५ मेदिन्यांतवनिपतति नपदंवक्त्रवल्लभेतिगर्वे
ण आश्लिष्यकैर्नतरुणीस्फुरीववसनैर्विमुक्तासि ९६ मूलेनिसर्गमधुरंसमर्पयंतोरसंपु
रोविरसाः इक्षव इवपरपुरुषाविविधेपुरहःसुनविधेयाः ९७ महतिस्नेहेनिहितः कु
सुमंवक्त्रदत्तमर्चितोवक्त्राः वक्रस्तदपिन्नानैश्वरइवसखिदुष्टयहोदयितः ९८ मात्रा
वरतरुणिपीवरवक्षोरुहयोर्भरेणमजगर्वं निर्मोकैरपिशोभायायोर्भुजंगीभिरुन्मुक्तैः
९९ ममकुपितायाःछायांभूमावालिंग्यसाविमिलत्पुलकः स्नेहमयपचमनुक्तककरोति
किंनैषनापरुषं ५०० मुषितइवकरुणाविरहेरिपुरिवकुसुमेषुकेलिसंग्रामे दासइवश्र
मसमयेभजन्ततांगंनितृप्यामि १ मुंचासिकिंमानवतीव्यवसायाद्विगुणमन्युवेगेति
ल्लेहमवःपयसाग्निःशांचेनचरोषमुन्मिषति २ मलयजमपसार्यघनवीजनाविघ्ना
विहायवाक्त्रम्यां स्मरसंतापादगणितनिदाघमालिंगनेमिथुनं २ महतोपिहिविश्व

गा० स्वा० ३०

सान्महान्त्यायादधतिनात्ममपिलघवः संवृणुतेऽद्यानुदधिर्निदाघनघोनमेकमपि ३ मधु
धारेवनमुंचत्तिमानिनिनिरुद्धापिमाधुरीसहजा कृतमुखमंगापिरसंददासिममसरिंदिवा
मोघैः ५०४ मदनारूढधनुर्ज्याघोनैरिवगृहीतापथिकतरुणानां वीणातंत्रीझ्कारोः के
षांनविकल्प्यतेचेतः ५ ममनयमस्याःकोपोनिर्वेदोस्याममापिमंदाक्षं यातंकचांतरि
क्षेस्मिनसंवृतिनमितकंधरयोः ६ मुक्ताबरैवधावतुपततुमखेसात्रिमार्गगावास्तु॥
इयमेवनर्मदाममवंद्याघनवातुरूपरसा ७ मृगमदलेपनमेनंनीलविचोलेवनिन्द्रा
निषेवस्वकालिंद्यामिंदीवरवमिंदिंदिरसुंदरीवसखि ८ ममममसख्यानयनपदेमिलितः
त्राक्रोनकश्चिदपिचलितुं पतितोसिपथिकविषमेघटूकूटीयेकुसुमकेतो ९ मह
ताप्रियेणनिर्मितमप्रियमपिसुभगसत्यतांयाति सुतसंभवेनयौवनविनाशनेनख
लुखेदाय १० मानग्रहगुरुकोपादनुदयितान्येवरीवचनेमस्य कांचनमयीवकूषा राम० ३०

राहांचितसुकृतावेव ११ पूनःकंटकविटपानिषांचलयाहिणाल्यजंतीसा वनइव
घुरेपिविचरतिपुरुषंचामेवजानंती १२ युष्मास्वपगतास्मोविबुधावाड्मात्रपाटवेन
वयं अतर्भवतिसवस्त्रपिनाभक्तस्तत्वविज्ञातं १३ यत्रनपूतीयत्रक्लिग्धानदृष्टो
पिनिपुणायानिहिताः नगिरोद्यापिव्यक्तीकृतःसजारोतुमरणेन १४ यानीयतेस
नाम्राद्मविनययावर्जितांभुजंगेन यस्मुमुनायाइवतस्याःसखिमलिनंजीवनंमन्ये १
५ यस्मिन्नयनयोपियन्नोक्ताविघ्नोमानएवदोःसोल्पं लघुताणुणानताकिंनवोसुवा
सखिनतेदृष्टः १६ यदीनसतेखलानांमाहात्म्यंकापिदैवयोगेन काकानामिववक्त्रो
क्लांतदपिहिनचिरादनर्थाय १७ यत्खलुखलमुखकुलवहुविनिहितमपिसुधिमे
वपरमेति तदनलंत्रोचमिवांशुकमिहलोकेदुर्लभंप्रेम १८ यन्नावधिमनुमनुते
पाथेयार्थंददातिसर्वस्वं नैनानयातिदारुणाशंकामारोपितचेतः १९ यूनामीव्यवि

गो०आ० रंविनवनातरुणीवक्ररुचिरा तवजघनेनाकलितानिखिलापत्नीखलेनेव २०
३१ यावज्जीवनमावीतुल्यानायपोर्निंतांतनिर्भेदः नदयोरिवैषयुवयोःसंगोरसमाधिक
माबाहतु २१ यन्निहितांशोरवरयसिमालांसायातुत्रागमवंतमिति प्रहरंतीशिर
सिपदास्मरामिगुरुगर्वकोपांतां २२ यौवनगुप्तिंपत्येवश्रुस्मुस्तुधचमार्जवंगुरुस्नु॥
कुर्वाणाहलिकवधूःश्वश्रास्यतेस्माजतोयुवभिः २३ योनगुरुभिर्नमित्रैर्नचविवेकेनापि
रिपुहसितैः नियमितपूर्वःसुंदरिसविनीतचंयानीतः २४ यन्मूलमार्द्रमुदकैःकु
सुमंप्रतिपर्वफलभरःपूरितः क्रमतन्माद्यसिवीचीपरिचयपरिणाममविचिंत्य॥
२५ यस्यांकेस्मरसंगराविश्रांतिप्रांजलिःसखीस्वपिति सवहतुगुणाभिमानेमदन राम०
धनुर्वल्लिचोलइव २६ यदिदानगंधिमात्राद्धसंतिसमक्षदेपिदंतिन्याः तत्किमदे ३१
नमलिनांकरीकपोलस्थलींवहति २७ यदवधिविद्रुमात्राविकसितकुसुमोत्करा

बाणश्रेणि पीतांशुकप्रियेयंतदवधिपत्नीपतेःपुत्री २८ यमुनातरंगतरलंनवकुव
लयंकुसुमजाविरतवसुलभं यदिसौरभानुसारीझंकारीभ्रमतिनभ्रमरः २९ येभिर
सिविनिहिताश्चापिनवंतिनसखेसमानसुपदुःखाः विकुराइवतेबालाएवजरापांडुता
वेपि ३० यन्नियातनिर्गुणायन्नवंनाजेयच्च।नित्यनिर्वाणां।किंकर्मस्तन्निहितंधनुष्पदे
हेवाराजेन ३१ यादक्षिणाचमस्यामदक्षिणोदक्षिणास्तदितरस्यां जलधेमध्यस्थःस
न्नवेलयोःसहृन्नामाचरसि ३२ युगपत्क्वापिघनोस्तनपिधानविधुरेत्रपास्मिताक्षमुखि
।।लोलाक्षिनैषपवनोविरमतितववसनपरिवर्त्ती ३३ यद्यपिबद्धःशैलैर्यद्यपिगिरिम
थनमुषितसर्वस्वः नदपीक्रमीतमधुरस्त्वायांदीक्षितोजलधिः ३४ यस्यांदिनीयस्य
तरोर्यामेत्यन्निशायांयथोन्नतग्रीवं देहासुधांशुरेखानिचांचकोरस्तथानयति ३५ यत्रा
जर्वैबलघिमागरिमाणंवक्रतांननुते छंदःशास्त्रइवास्मिन्लोकेसरलःसखेकिमसि ३६

गो०स्वा० ३२

यत्रोपकारंयत्रनृपाणांयत्रकोपमातनुते गुरुणापितेनकार्यंपदेनकिंश्रीपदेनेव
३७ मृगपतेर्नुवकश्चिन्महिमानस्यानुरूपइहविटपी येरयदिनेनिदाघद्राघीयःक्लमा
सुनेच्छाया ३८ यद्यपिचंदनविटपीफलपुष्पविवर्जितःकृतोविधिना निजवपुषैवत
थापिहिसहरतिसंतापमयुरेषां ३९ राज्याभिषेकसलिलक्षालितमौलेःकथासुकुल
स्य गर्वभरमंथराक्षीपश्यतिपदपंकजंराधा ४० रतिकलहकुपितकांताकराचिकु
राकर्षमुदितगृहनाथं भवतिभवनंतदन्यत्रमंत्राःपर्णशालावा ४१ रोगीराजायत
रतिजवांवादंसत्यमद्यकजयामि आरोग्यार्थछकेचयितव्योपांतोगतेसुमेग ४२ रूदस्व
रसभ्रमरस्याभिन्निरस्यनेनतंप्रियंप्रतिमे श्रोतसइवनिम्नंप्रतिरागस्यद्विगुणश्रावेगः ४३ रू
पमिदंकांतिरसावयमुत्कर्षःसुवर्णरचनेयं दुर्गतमिलिताजलितेन्नमसिप्रतिमंदिरद्वारं ४४
रचितेनिकुंचपत्रैर्निस्रुक्पात्रेददासिमावज्ञा पर्युषितमपिस्मृतीन्द्राश्वासकहनंवधूस्त्र ४५

राम० ३२

स्कृतिनसखिनिजस्थितिमजस्रुस्थापयतिनायकःसयथा तिष्ठतितथैवतद्गुणविद्येयंहारयष्टि
रिव ४६ राजसिकृतांगिमंगलकलशीसहकारपल्लवेनेव तेनैवचुंबितमुखीप्रथमाविर्भू
तरागेण ४७ रूपगुणहीनमार्यामवतिलघुर्धूर्जिरनिलचपलेव छथयतिपृथुगुणनेयात
गुणितरणाविगरिमाणं ४८ रागेनवेविद्रुमतिविरहक्षमंदमंदाक्षैः॥सस्मितसलज्जमी
क्षितमिदमिष्टंसिद्धमाचष्टे ४९ रोषोपिरसवतीनांनककर्शोवाचिरानुबंधीवा वर्षाणामुप
लोपिहिसुस्निग्धःक्षणिककल्पश्च ५० रोदनमेतद्धन्यंसखिकिंबकुमृत्युरपिममानर्घ्यः॥
स्वप्नेनवहिविहितोनयनमनोहारिणातेन ५१ रोषेणैवमयासखिवक्रोपिग्रंथिलोपिकठि
नोपि ऋजुतामनीयताद्यंसद्यःस्वेदेनवंशइव ५२ जनीमियमुपनेतुन्निभसूःप्रथमसु
पतस्थे॥रंजयतिस्वयमिंदुकनापकंदृष्टहृतीव ५३ जग्रीसिक्लबर्त्मनिसुस्निग्धेवर्त्तिहि
वदग्धासि श्रयमखिलनयनसुभगोनत्पुरुमुक्तांपुनःस्पृशति ५४ लक्ष्मीःत्रिाष्ट्यतिगु

गो० श्या० णानमृत्युनर्द्दुर्गतिर्विधूनयति पूर्णामिवतिसुहृन्मस्तुषारुचिरपचयेवक्त्रः ५५ लूतांतंतुनिस
ऋद्वारःशून्यालयःपतत्यतगः पथिकेतस्मिन्नंचलपिहितमुखोरोदितीवसखि ५६ लग्नंज
३३ घनेतस्याःसुविशालेकलितकरिकरक्रीडे वप्रेसक्तंद्विपमिवशृंगारस्तंविधूनयति ५७
लिप्तंनमुखंनांगंनपल्लवीनवरत्नाःपरागेण अस्पृष्टातेवनलिन्याविदग्धमधुपेनमधुपीतं
५८ लग्नंजघनेतस्याःशुष्यतिवत्खलन्मानसंममच तत्कृत्रिमविभ्रमवेदानमिदमधिक
सरागसाबाधं ५९ लज्जयितुमखिलगोपीनिपीतमुनसंमधुद्विषंराधा अत्रैवष्टल्लतिक
तिकथांतांमोर्दयितार्द्धतुष्टस्य ६० लक्ष्मीनिश्वासानिलपिंडीकृतदुग्धाजलधिसारस्तुजः॥
क्षीरनिधितीरसदसोयत्रांसिणायंतिराधायाः ६१ लीलागारस्यबहिःसखीषुचरणान्तिथौ राम०
मयिप्रियया प्रकटीकृतःप्रसादोदत्तावातामतेन्यजनं ६२ वसाधृतंनललाटेनलुलितं ३३
मंगंनचाधरैदंताः तुठत्यलमहारिवारिचनस्पृष्टमुपाघवतुरेणा ६३ व्यालंविचूर्णकृत

लचुंबितनयनांचलेमुखेतस्याः बाष्पजलबिंदवोलकमुक्ताइवपांथनिपतंति ६४ वि
नयविनतादिनेसौनिन्द्रामदनकलाविलासजमदंगी निर्वाणाक्षलितौषधिरिवनिपुणा
प्रत्यभिज्ञेया ६५ विहितबहुमानमौनासखीषुरोधैर्यदंभमातनुते राणात्रीकाकुयांचा
लघुवीक्ष्यारहसिपुनरोषा ६६ विषमन्मारविषिखभिमालापल्लीत्रारणायमेकमभिलपति
॥तस्यतवच्छायेवस्त्रीयाजायाप्रियम्नमिः ६७ विविधायुधप्रणाबुदविषमेवक्षस्थलेप्रिय
तमस्य श्रीरपिवीरवधूरपिगर्वोत्पुलकामुखंस्वपिति ६८ वैमुख्येपिविमुक्ताःप्राराइवा
न्यायपयोधिनोवितनोः निर्दतिपृष्टपतिताःप्रियहृदयंममतवश्वासाः ६९ व्यक्तमधुनास
मेतःखंडोमदिराक्षिदत्तानवसनेते यत्रवसुधैकसारंलोमिनितांकिमपिनाद्राक्षं ७०
बालाविलासबंधारप्रभवस्मनाभिविंतयन्पूर्व सन्मानवर्द्धितांतांगृहिणीमेवानुशोचामि
७१ बीजयतोरन्योन्ययूनोर्वियुतानिसकलगात्राणि सन्मैत्रीवक्षोणीपरंनिदाघेपिनवी

घटिता ७२ व्यारोपंव्यानिन्यास्तमोदिवःकासरेकलमंभूमेश्च बद्धमलिंचनलिन्याःप्रना
तसंध्यापसारयति ७३ वक्तुविहंसमाणोस्त नसिन्नंत्रुटतिकंचुकंतस्याः पूर्वदयितानुरा
गस्तवहुदिनमनागपित्रुटति ७४ व्यक्तिमवीक्ष्सतन्यातस्यामेवेतिविदितमधुनातु हर्म्यह
रिमुखमिवत्वामुभयोःसाधारणांवेद्मि ७५ व्यजनस्येवसमीपेगतागतैस्तापहारिणोम
वतः अंचलमिवचंचलनांममःसख्याःआपितंचेतः ७६ वितरंतीरसमतर्मुमाङ्गनावंतनो
पितनुगात्रि अंतःसलिलासरिदिवनिवससिहृदि बहिरदृश्यापि ७७ विहितविविधा
नुबंधैमानोन्नतयावधीरितोमानी लमतेकुतःप्रबोधंसजागरितैवनिद्राणः ७८ व्रीडा
विमुखीवीतस्नेहामान्नांकाकाकुवाङ्मधुरे प्रेमार्द्रसापराधांदिनातिदृनांबहुमेबाला ७९
बाष्पाकुलंप्रलपतोगृहिणिनिवर्त्तस्वकांतगच्छेति यातंदंपत्योर्दिनमनुगमनावधिसरस्ती
रे ८० वक्त्रःआयितिसांद्रश्वासेवाङ्मात्रसुभटिघनघर्मे सुतनुललाटनिवेशितललाटि

केतिष्टविजितासि ८१ विचरतिपरितःकृष्णोराधायांरागचपलनयनायां दत्वादिग्विधविस्तृतंवि
शिखंविदधातिकुसुमेषुः ८२ वीक्ष्यैववेत्तिपथिकःपीवरबकुवायसंनिजावासं सौंदर्यैक
निधेरपिदयितायास्त्वरितमविचलितं ८३ विमुखेचतुमुखेपिश्रितवतिचानन्यजावमानोपि
॥मग्नांमहीनिस्तारेहरिःपरंसधरोमाभूत् ८४ वापीकच्छेवासःकंटकवृतयःसजागरास्ना
मराः केतकिविटपिकिमेतैर्ननुवारयमंजरीगंधं ८५ विचलसिमुग्धेविधृतायथातथावि
शासिहृदयमिदमदये शक्तिःप्रसूनधनुषःप्रकल्पलक्ष्संस्पृशंतीव ८६ विहितासमशर
समरोजितगांगेयछविःशतारोपः पुरुषायितेविराजतिदेहस्तवसखिशिखंडीव ८७
वृत्तिविवरनिर्गतस्यप्रमदाबिंबाधरस्यमधुपिबते अवधीरितपीयूषःस्पृहयतिदेवाधिरा
जोपि ८८ वासितयधुनिवधूनामवतंसमौलिमौलिमंडलेयूनां विलसतिसापुरकुसुमे
मधुपीववनप्रसूतेषु ८९ व्रीडाप्रसरःप्रथमंतदनुचरससाविपुष्टचेष्टयं रजनीविनिर्गमा

दिवनटीवदयितामनोहरति ९० वाससिहारिद्रइवचयिगौरांग्यानिषेवितोरागः पिशुनेन
लोपनीतःसहसातपताजलेनेव ९१ विश्वग्विकासिसौरभरागांधन्याधवाधनीयस्य कवी
दयिकुरंगनवतोनाम्नीमाशयनस्थानं ९२ वटकुटजतालतालमलिरसालवकुवारसिंधु
वाराणां अस्तिनिदामलयाचलसंभवसौरभ्यसाम्येपि ९३ विनिहितकंदर्पकोटिचापल
दोषेणान्यांकुरंमुक्त्वा वटमेकमनुसरंतीजाह्नविलुवमिवप्रयागतटे ९४ वेदरजनीचतुर्णां
प्रहराणांसंगमेवियोगंच चरणानामिवकूर्मीसंकोचमपिप्रसारमपि ९५ इतिविवरणा
क्रांतीसुभगचामीक्षितुंसखीदृष्टिः हरतिसुवद्हृदयपंजरमध्यस्थामन्मथेवुरिव ९६ विपु
णितुलासामान्येमागणयेनंनिरूपणेनिपुणा धर्मधटोमावर्धरिकरोतिलघुमुपरिनयति
गुरु ९७ वासरगम्यमनूरोरंबरमवनीचवामनैकपदं जलधिरपिपीतलघ्वःसतामन

ःकेनतुलयामः ९८ वितततमोमसिनिजेषालक्ष्मोसंगस्फुटाकुरंगाकि पत्रानूरनिकराइ

वत्ताराप्रकराविराजंते ९९ वपुषानुजंगसंगमसहेनतरुणितवागुरुनितंबेन नक्तुधो
गंभीरःकोजलधिर्मंदरेणेव ६०० विविधांगभंगिषुगुरुर्नूतनशिष्यामनोनवाचार्यः वे
त्रलतयेवबालांतल्पेनर्तयतिरतरीत्या १ विपरीतमपिरतंतेस्रोतोनद्याइवानुकूल
मिदं तटतरुमिवममहृदयंससमूलमपिवेगतोहरति २ वैभवभाजांक्षणमपिनृप
णापरूणवनिष्किंमं गुणामात्मनामधर्मद्विषंचगृह्णंतिकाणादाः ३ वक्राःकपटस्निग्धा
मलिनःकर्णांतिकेप्रसज्जंतः कंवंचयंतिनसखेखलाश्वगणिकाकटाक्षाश्च ४ विक्ष
कालावलयितजलधरपिवरोदराहिनिर्यांति विषदौदनकृतिमुषःप्रेयसिपयसास
मकरकाः ५ व्यजनादिभिरुपचारैःकिंमरुपथिकस्यगृहिणिविहितैर्मे तापस्तवहरु
कदलीद्वयमध्येशांतिमयमेति ६ विगुणामपिहंतमहतावनिर्मितंभवतिकर्मशोभा
ये दुर्वहनितंबमेथरमपिहरतिनितंबिनीनृत्यं ७ वीक्ष्यसतीनांगणनेरेषामेकांततः

गो० आ०
३६

स्तनाभोगं संतुयुवानोहसितंस्वयमेवापास्निावरितुं ८ विंध्याचलइववेहस्तवविविधा
वल्लीमर्दनितंबः स्थगयतिगतिंमुनेरपिसंभ्रावितरविरथस्तंभः ९ हृतिमंजनसहतिका
मसुह्रामदुर्नयाराम परवाटीस्रातल्लंपटदुष्टंवृषस्मरसिगेहमपि १० वंशावलंबनंपश्यो
विस्तारोगुणास्ययावनतिः नक्राजस्यखलस्यचनिजांकसुमग्रणाम्नाय ११ विंध्यमहीध
रशिषरेमुदिरश्रेणीरूपाणामयमनिलः उद्घद्धिक्षज्योतिःपथिकवधायैवर्त्मानयति १२
व्यालंबमानवेणीयुतस्थूलिम्रथममस्फणाधौतं आयातस्यपदंममगेहिन्यास्तदनुसलिलेन
१३ वक्षःस्थलस्पृष्टंममसुषमुपधातुंनमौलिमालम्रसे पीनोत्तुंगस्तनभरदूरीभूतंरतश्रांता।
१४ वदनस्यापारांतर्गावादनुरक्तमानयंतीचं दूतीसतीनांसाचंतस्यभुजंगस्यदंष्ट्रासि १५
इतिवकारवज्या श्रीरपिभुजंगभोगेमोहनविजेनशायितायेन सोपिहरिःपुरुषोयदिपु
रुषाइतरेपिकिंकूर्मः १६ नांकेयास्थैर्यमयीत्रथयनिबाक्तमनोभवस्यापि दर्पणलामिव

राम०
३६

नवनीकतरुस्तारुणोक्तिवालयति १७ न्याह्लेनखरभंगुरकवोरस्तरजातरूपरचनोपि बाला
नामपिबालासायस्यास्त्वमपिहृदिवससि १८ कृतरावक्रतिहारिणिरागोकर्षेणकंठम
धिवसति गीतइवचयिमधुरेकरोतिनाथश्रहंसुतनुः १९ श्रीःश्रीफलेनराज्यंनृणांराजे
नान्यसाम्यतोलब्धं चकुचसम्यकाभ्याकृतोघटस्तकवर्तिचं २० श्रोणीभूसावंकेप्रिये
नयंमनसिपतितुजेमौलिः गूढश्वासोवदनेसुरतमिदंचेन्नृणांत्रिदिवं २१ स्निग्ध्यालिवधु
वल्लिवपश्यल्लिवचोछिषल्लिवान्तमः दग्धदिवहृदयस्यांतःस्मरामितस्याःसखेजघनं २२॥
शिरसिचणाप्रहारंप्रदायनिःसार्यतांसतेतदपि चक्रांकितोभुजंगःकालियइवसुमुखिका
लिंद्याः २३ शोच्येवसाकृत्यांगीभूतिमयीनवतुगुणमयीवापि स्नेहैकवत्स्यनवतास्य
कादीपेनवर्तिरिव २४ शुकइवदारुत्रालाकापंजरमनुदिवसवर्द्धमानोमे कृंततिदयि
ताहृदयंशोकः स्मरविशिखतीक्ष्णमुखः २५ क्वचाकस्मिकमरणाच्छुकसूनोःसकलको

तुकैकनिधेः त्रातोगृहिणीविनयव्ययस्त्रागत्यैवपथिकेन २६ त्रीलितभुजंगभोगाक्रो
डेनाम्भकृतापिच्छलेन श्वचलैवकीर्त्यतेभूः किमत्राकूनामवसुमत्याः २७ त्र्यामावि
लोचनहरी बालेयंमनसिहंतसक्रंती लुंपतिपूर्वकलत्रंधूमलताभित्तिचित्रमिव २८ त्रा
तत्रोगतिराद्वृत्तिः त्रातत्रः कंगवलंबनंत्रातथा त्रातत्रोयामीतिवचःस्मरामितस्याःप्रवा
सदिने ॥ २९ कृतपरपुष्टरवाभिःष्टष्टोगोपीभिरभिमतंकृष्णः त्रांसतिवंशास्तनितैस्तब्धी
निनिहितलोचनोनुमतं ३० त्रांकरभिरसिनिवेषितपदेतिमामदमुपावहेंडुकल्पे फल
मेतस्यत्रविष्पतितवचंडीचरणरेणुभृजा ३१ त्राखिभिःखरेसमीरणदोलायितनाडनि
वृतंवसति कर्मैकत्रारणामगणितनयमभिमिथिलकेलिखगमिथुनं ३२ शुकसुरतसम राम०
रनारददूदयरहस्यैकसारसर्वज्ञ गुरुजनसमक्षमूकप्रसीदजंबूफलंदलय ३३ निरसा ३७
वहसिकपर्दरुद्ररुद्धिचापिरजतमर्जयसि स्वस्याप्युदरस्यार्धंनरतस्तवदैवैत्तिकस्तचं ३४

श्रोतव्यैवसुधेवस्थेतांशुकलेवक्रूरहस्यैव दुष्टभुजंगपरीतेचंकेतकिनखलुनःस्पृश्या ३
५ श्रवणोपनीतगुणायासमर्पयित्वाप्रणाम्यकुसुमानि मदनधनुर्लतयेवत्वयावत्रोहंतनी
तोस्मि ३६ त्राखोटकत्राखोटजवेखानसकरटपूज्यरटरुचिरं नादरपदमिहगणका
:प्रमाणपुरुषोभवानेकः ३७ त्राभिरेखोपमकांतेस्तवान्यपाणिग्रहंप्रयातायाः भ्रदना
सिपुत्रिकायाइवांगमोभाकदर्थयति ३८ त्रोथिल्येनधृताअपिभर्तुःकार्येनत्यजंतिसु
हृत्राः बलिनाकृष्टेबाहौवलाःकलंतिधावंति ३९ दृतित्राकारप्रज्या षड्दरणाको
टजुष्टंपरागपुणपूर्वैर्णामायुधंत्यक्ता चामुष्टिमेयमध्या मधुनात्राक्तिस्मरोहरति ४०
सादिवसयोपकृत्यव्यपदेशात्तस्यकेवलंगृहिणी दितिथौदिवसस्यपरानोथिरिवसे
व्यानिभिचमसि ४१ स्नानन्तूतननस्वलेखाजंबातवयमबिंदुसंदोहः श्रासातिपद
स्वनेप्रविन्ताविवमौक्तिकप्रसरः ४२ सौनाय्यगर्वमेकाकरोतुभूथस्यभूषणंकरिणी

॥ गुप्तायासरतोयामिदंधयोर्मध्यमधिवसति ४३ स्वचरणपीडानुमितचन्द्रमौलिरुजा
विनीतमानस्या अपराधासुभगचांस्वयमहमनुनेतुमायाता ४४ स्नेहमयान्पीडय
तोवृथैवचक्रं हितैलकारस्य चालयतिपार्थिवानपियःसक्कुलालःप्रपंचको ४५ ॥
सरलेनवेदमवतीबङ्गांगाबङ्कुरसाबङ्कुविवर्त्तीच गतिरसतीनेत्राणांश्रेणांको
तस्वतीनांच ४६ सखिमध्याक्षिगुणाक्षमणिकरश्रेणिपीडिताछाया मञ्जतुमि
वालवालेपरितस्तरूमूलमाश्रयति ४७ सखिशृणुममत्रियोयगेहंयेनैववर्त्मनाय
तः तन्नगरग्रामनदीःपृच्छतिसममागतानन्यान् ४८ सायंरविरनलमसौमदन
न्नरंसववियोगिनीचेतः इदमपितमःसमूहंसोपितनोनिर्भरंविशति ४९ स्मरस
मरसमयपूरितकंबुनिभोद्विगुणपीनगलनालः नीर्णाश्वासादोपरिजिगीषुरिवक
लरवःक्वणति ५० स्फुरदधरमविरताश्रुधनिरोधोकंपकुचमिदंरुदितं जानूपनि ॥

हितनेहस्तन्यस्तमुखंदाक्षिण्यप्रकृतेः ५१ स्वयमुपनीतैरसनैःपुष्पंतीनीडनिहितंदयितं स
हजप्रेमरसज्ञासुभगागर्वंवकीवहति ५२ स्वरसेनवधूतांकरमादानेकंटकोत्करैस्तुहृतं
॥ पिशुनानांपनसानांकोयासोगेप्यविश्वास्यः ५३ सौभाग्यंदाक्षिण्यात्मनल्पपदिष्टंहरेणात
रुणीनां वामार्द्धमेवदेव्याःस्ववपुःन्निल्पेनिवेशयता ५४ सुभगस्वमगवननिर्भीनवता
संमर्दपीडितासुतनुः सापीडयेवजीवतिदधतीविग्रहेषुविरूपं ५५ सागुणमयीस्वभावस्व
च्छासुतनुःकरग्रहायत्ता भ्रमिताबङ्कुमंत्रविदासवताकात्ममीरमालेव ५६ सव्रीडस्मि
तसुभगेस्पृष्टास्पृष्टेवकिंविदधयांती अपसरसिसुंदरियथायथातथामेमनःस्पृशसि
५७ सखिसुखयत्यवकाशाशाप्रत्ययान्यथातथानगृही वातादवारितादपिभवतिगवाक्ष
निलःशीतः ५८ संततमरुणसुखीसखिनिगिरंतीगरलमिवंगिरांगुंफं अविगणितौष
धिमंत्राभुजंगिरक्तांविरंजयसि ५९ सुदिनंतदेवयत्रस्मारंस्मारंवियोगदुःखानि आलिंगति

सागाढंपुनर्यामिनिप्रथमे ६० सांतर्भयंभुजिष्यायथायथाचरतिसमधिकंसेवां सान्याकर्
ष्यसमयान्तथान्तथागेहिनीतस्याः ६१ सुंदरिदृग्रयतियथानवद्विपक्षस्यतन्नखीकांति॥
पततितथाममदृष्टिरब्दे कदाप्यस्य सोमूया ६२ स्वाधीनेरधरव्रणानखांकपत्रावलोप
दिनत्रायनैः सुभगासुभगेत्यनयासखिनिखिलामुखरितापल्ली ६३ सरितइवयस्यागेहे
शुष्यंतिविन्नालगोत्रजानार्यः ज्वारास्वेवमनूप्यनिजजलनिधिलहरीषुजलदइव ६४ स
कलकटकैकमंडनिकठिनीभूतान्नायेन्द्रिरवरदंति गिरिवरमुवइवमन्येमनःशिलासम
नवचंडि ६५ सखिडुरवगाहेमानोविदग्धानोविप्रियंप्रियेपिजने खलइवडुर्लक्ष्यस्तव
विनयमुखोपस्थितःकोपः ६६ स्थलकमलमुग्धवपुषासातंकांकस्थितैकचरणेन॥
आश्वासयतिविसिन्याःकूलेविसकंटिकान्नाफरं ६७ सनखपदमधिकगौरंनाभीमूले
निरंशुकंरुचा अनयोसेवितपवनचंकिंकृतमलयमृगुपातः ६८ सर्वांगमपर्यंतीलै

नासुभंभ्रमेणशय्यायां अलसमपिसाग्यवंतंमजनेपुरुषायितेवक्त्रीः ६९ स्वेदमचैलम
तासमपदीससमंडलीयांती समदनदहनविकारामनोहराव्रीडितानमति ७० स्मरस
मवन्मानःसंयातोयंसमानरत्नानां तैरेवनिर्मलरत्नैर्गुंफितःकाव्यसर्गइव ७१ सखावा
सामेवसखेपयइवसुरतंमनोहारि तस्याएवपुरतःपुनरावृत्तोदुग्धमिवमधुरं ७२ स्वप्नेपिमां
नमुंचसियातेमुखमामिनीदृष्टिरत्नापि दुष्टांनबुद्धिमिवतांगूढव्यभिचारिणींवेत्सि ७३ सप
रावृत्तिचरंतीवान्येवनृणांमनोनवद्यानि हरसिद्धियसिनरजयसिक्रमयसितोलयसिधुनोषि
पातयसि ७४ सावाकूलकृष्णानावाक्षीमात्रंवेत्तिकितवतवतुल्यं कोटिर्वराटिकावाद्भुतवि
धेःमर्वणावपणः ७५ साविरहदहनहूनामृचामृचापिजीवतिवराकीसारीनकितवभवता
नुकूलितापातिनाक्षेण ७६ स्वप्नादिवस्वेदंजनयतिनचमेददातिनिद्रातु ग्रीष्मइवजघनां
शुकमपिननिदाघःक्षणमपिक्षमते ७७ सामवतोमावनयासमयविरुद्धंमनोभवंबाला नू

तनलतेवसुंदरदोहदश्रद्धाफलंवहति ७८ स्मृत्वातिनखैर्नचविलिखतिसिचयंगृह्णातिन
चविमोचयतिनचमदयतिनयतिनिद्रांसानतिद्राति ७९ स्तनजघनद्वयमस्याःलंघितमध्य
ःसखेममकटाक्षः नोल्लतिरोधस्तस्यास्तद्वयंतीर्थकाकइव ८० सव्रीडस्मितमंदश्वसितं
मामांस्मृत्वेतिनल्पंत्या आकोपमेत्यवातायनंपिधायस्थितंप्रियया ८१ सकरग्रहंसरुदि
तंसाक्षेपंसनखमुष्टिसजिगीषं तस्याःसुरतंसुरतंप्राजापत्यःक्रतुरतोन्यः ८२ सख्या
इतिरामबलैर्यन्यंस्नानान्नायेयपयोराशेः नेत्रोल्लासितिमंतोहंतलघिम्नैवबकुमानः ८३॥
सखिनखलुनिर्मलानांनिदधत्संनिधानमपिमुखेमलिनाः केनाश्राविपिकानांकुहूविहा
येतरःशब्दः ८४ सान्यामातन्वंगीदहतात्रीतोपचारतीव्रेण विरहेणपांडिमानंनीता
तुहिनेनदूर्वेव ८५ सुनिरीक्षितनिश्चलकुरवल्लभथाराजलोलितानतथा सोत्कंपेन
मयासखिसादृश्यमाद्यतिस्मयथा ८६ सखिमोघीकृतमदनेपतिव्रतेकस्तवादरंकुरुते

॥श्रोषीर्जगवानपिसकामविद्रोहरःप्रज्यः ८७ सामयिनदासबुद्धिर्नरतिनापत्रपानदि
श्वासः हंतनिरीक्ष्यनवोढामन्येवयमप्रियाजाताः ८८ सुचिरायातेगृहिणीनिद्रामुक्ता
दिनमुखेविदध्येयं धवलनखांकानिजवपुरकुंकुमाङ्केनदर्शयति ८९ स्तनजघनो
ःप्रणायीगाढंलग्नोनिवेशितस्नेहः प्रियकालपरिणतिरियंविरज्यसेयन्नखांकइव ९०
साविच्छायानिद्रानिद्रासुतनुर्वक्रतुहिनद्युतिनवेतन्ये कूलतिचदीयविरहादोषधिरि
वहिमवतःपृष्ठे ९१ सानीरसेतवहृदिप्रविशतिनिर्यातिनलभतेस्थैर्यं सुंदरसखीदि
वसकरवीवेतुहिनांशुरेखेव ९२ सुकुमारचंकांतिर्नितांतसरसचमांतराश्चगुणाः॥
किन्नामलेंडुलेखेंद्रनाग्रहेणवतेकथितं ९३ सौरभ्यमात्रमनसामास्तांमलयक्रमेषुन
विशेषः धर्मार्थिनासमृद्धयस्तथापिपूजार्थमन्यत्रः ९४ संवाहयतिन्यायानंपथोपवीजय
निरहीणी गृहवृतिविवरनिविशितदृत्वास्तथाश्वासनंयूनः ९५ सत्संसख्यगुणाभुक्ताध्या

गो० आ०
४१

सद्दष्टोपुनर्भुजंगेसा अर्पितकोटिःप्रणामतिसुंदरहरचापयष्टिरिव ९६ सर्वंसहांमही
मिवविधायतांबाष्पवारिभिःपूर्णां भुवनांतरमयममधुनासंक्रांतस्तवगुरुःप्रेमा ९७ सं
भवतिनखलुरक्षालालनानांप्रकृतिचपलचरितानां अनुभवतिहरशिरस्यपिभुजंगप
रिखीलनंगंग ९८ सुलभेषुकमलकेसरकेतकमाकंदकुसुमेषु वांछतिमनोरथांधोम कु
धुपीस्मरधनुषिगुणभावं ९९ सालंकिताममत्रीकुपितान्नीतःप्रियःसखीसुखिता॥
बालायाःपीडयांनिद्रानिनेजागरैर्वैद्यैः ९९ सुचिरागतस्यसंवाहनछलेनांगमंगमालिंग्य
॥पुष्पतिचमानवर्चांगृहिणीसफलयतिचोकलिकां १०० सासर्वथैवरक्तारागंगुंजेवनतु
मुखंवहति वचनपटोस्तवरागःकेवलमास्येशुकस्येव १ सायंकांतभुजांतरविनिपतितानि रम०
खिलनीतरजनीसा उषसिदत्प्रदीपंसखीस्वीनिरूपहस्यतेबाला २ सातीक्ष्णमानदह ४१
नामहतःस्नेहस्यदुरनुगःपाकः चांदवीमिवहतिप्रियासयत्नास्मिविश्वस्तः ३ स्नेहकृतिर्जि

गीषासमरःप्राणव्ययावधिःकरिणां नतत्सुतेकमनर्थंदंतिनितवयौवनोद्भेदः ४ सदन
दर्पेतिदयितोहसतिसखीविव्रातिधरणिमिवबाला कुलतिसपत्नीकोरेजल्पतिमुग्धेप्रसी
देति ५ संकुचितांगीद्विगुणांशुकांमनोमात्रविस्फुरन्मदनां दयितांलज्जामिबालामिवतु
हिनचत्वसादेन ६ सखिलग्नेववसंतीसदाश्रयेमहतिरसमयेतस्य बाडवशिखेवसिंधो
र्नमनागप्यार्द्रतांभजसि ७ सखिमिहिरोऽमनादिभ्रमोदमपिधायसोयमवसाने वंध्यो
वधिवासरइवतुषारदिवसःकदर्थयति ८ सुरभवनेतरुणाभ्यांपरस्पराकृष्टदृष्टिहृदयाभ्यां
॥देवार्चनार्थमाहृतमनोन्यस्यार्पितंकुसुमं ९ सायंकृतोद्यायांतमधुपानोनिर्यतांनाद
॥मित्रव्यसननिषण्णैःकमलैराक्रंदइवमुक्तः ११० सुमहतिमन्युनिमित्तेमयैवविहिते
पिवेपमानोरुः नसखीनामपिरुदतीममैववक्षःस्थलेपतिता ११ सुभगजनविचाल
नशिथिलभुजाहृदयंक्यस्मापि उद्वर्तनसख्याःसमाप्यतेकिंचिदपगच्छ॥ १२ सव्रीडान

खरदनार्पणेषुकुपिताप्रगाढमपिरोढ वक्रयं वाचरणग्रहसाध्यारोषेणजातेयं २३ सु
सुगृहीतमलिनपक्षाज्जघवः परभेदिनपक्षाज्जघवः परभेदिनस्तीक्ष्णाः सुरूपाअपिविनि
र्वाणापिगुणाच्युताः कस्यनमयाय १४ स्वकपोलेनप्रकटीकृतंप्रमन्नचकारणंकिमपि वि
रदस्यदुर्जनस्यचमदंचकारेवदनमपि १५ सत्यंपतिरविदग्धः सातुसाधियैवनिधुवनेनि
पुणा मार्त्रिकमाधायगुरुंधनुरधिगतमेकलव्येन १६ सौभाग्यमानवान्सचयावधीया
प्रमानमानीतः त्वंविरहपांडिमानंभस्मम्लानोपमंकुरुते १७ सखिममकरंजैतेजेवकु
संदत्रांप्रहेष्यसीत्युदिता श्वसुरगृहगमनमिलितंवाष्पजलंसंहृणोत्यसती १८ संदर्शा
यंतिसुंदरिकिलदानांतमसिवितनमन्त्रिकल्पे मौलिमणिदीपकलिकावर्तिनिमानोगि
नोभानं १९ संतर्पणानृणानांविहितंपिहिताः सितांशुरविताराः प्रध्वस्ताः पंथानोमलि
ननोन्मयमेघेन २० संमुग्धमपिमान्यंवा पिशुणिनमपिकरगतंपिशुनाः जीवाकर्षणावी

नाधनुरिवयोधानमुंचंति २१ सम्यगनिष्पन्नः सन्योर्थस्वरस्यास्वयंस्फुटीक्रियते सम्यंगण
वनवतिप्रथमोविनतातनूजइव २२ सकृनणवहिर्विद्यान्तोनायैतनवतिदुर्जनेमोघा न
विहरदर्जनितयाकैश्चिदुपादीयतेगृध्रः २३ सुभगंवदतिजनस्त्वंनिजपतिरितिनेषरो
चतेमह्यं पीयूषैर्पीहिभैषजमावोपालितेनवल्यरुचिः २४ सोधगवाक्षगतापिहितदृष्टि
स्तांस्थितिकृतप्रयत्नमपि । हिमगिरिशिखरस्खलितागैवेणवतंहरति २५ सहधर्मचारि
णीमेपरिछदः सुतनुनेहसंदेहः नतुसुखयातितुहिनदिनछत्रछावेवसक्ती २६ स
कलगुणैकनिकेतनदमनववासेनधरूहराजा। जातोसिनूतजेवंसतामनादेयफलेकी
सुमः २७ सुंदरितांटंकमयंचक्रमिवोद्वहतितावकेकर्णे निपततिनिकामतीक्ष्णाःक
टाक्षबाणोर्जुनप्रणाची २८ स्वाधीनैवफलर्द्धिर्जनोपजीव्यचमुखयः छाया सत्युंसोम
रुहइवजीवनमात्रमात्रास्यं २९ संतापमोहकंपान्संपादयितुंनिहंतुमपिजंतून्॥

दुर्जनमूर्तिरिवैषा स्मरति मुग्धतवापांगः ३० सुखयतितरांनरान्तिमपरिचयलेत्रांगणा
गनेवश्रीः कुलकामिनीवनोक्तनिवाग्देवीजन्मजन्मापि ३१ स्वनिलयनिकटेनलिनी
मलिनवजातच्छदांनिरीक्ष्येव द्वारगृहिणीतिपृलपन्विरागतःसखिपतिःपतितः ३२
सखिचतुराननभावाद्वैमुख्यं क्वापिनैवदर्शयति अयमेकहृदयएवक्वहिणाइवद्वि
यतमस्त्वदपि ३३ सत्यंमधुरोनियतंवक्रोनूनंकलामयोदयितः सतुवेदनाद्वितीयाम
कलंकःप्रतिपद्विधुरिव ३४ स्वस्थानादपीविचलतिस्वमपिनीचमापिन्नजते निजपक्ष
णामनाःसुजनोमेनाकशैलइव ३५ संवृणुबाष्पजलंसखिदृशामुपरज्यांजनेचवर्त्रौ
नां दयितःपश्यतुपत्रलेपकोटितततरलत्रापकरश्च ३६ सापांडुदुर्बलांगीनयसि
चंयत्रयातितत्रैव कमिनीवकेतवविदोहस्तग्रहमात्रसाध्याते ३७ सखिविश्वगंज
नीयालक्ष्मीरिवकमलमुखिकदर्यस्य चंप्रवयसोस्यरक्षणमात्रोपयोग्यासि ३८

इतिमकारमज्या हृदयत्वयागवाक्षेविसहृद्धंकिमपिकूजितंसख्या यत्कलह
भिन्नतल्पान्नयकपटादेतिमांसुतनुः ३९ हरतिहृदयंश्रलाकानिहितांजनतंतु
रेषसखिमुग्धो लोचनबाणामुचानेनधनुषाकिणाइवोल्लिखितः ४० हसमिचरण
प्रहारेतल्पादपसारिणुविस्मपिषि नासहनोपिकृतेप्रियहृदयालुयनाच्चनिःसर
॥४१ हसतिसपत्नीस्वस्रूरोदितिवदनंचपिदधतेसख्यः स्वप्नायितेनतस्यांसुभग
चलामजल्पंत्यां ४२ हृदयंममप्रतिकृणाविहिताद्यत्रिःसखेप्रियात्रोकः प्रबलो
विदारयिष्यतिजलकलशांतीरवेलेव ४३ हंतविरहःसमंतात्कूलयतिदुर्वारती
व्रसंवेगः अरुणस्तपनशिलामिवपुनर्नमांमस्मतांनयति ४४ कुचोतटिनितं
बगौर्ल्मितोवक्रेपुनाव्रायेनिहितः फलदलवल्कलरहितस्त्वयांतरिक्तेनरुस्तक
४५ हृतकांचियवलवंधात्नवजघनादपरभोगमुक्तायाः उच्छ्वसितरोमाली

नाम्नितटेगरलल्लेखेव ४६ स्त्रीणास्मद्दयितेनुर्नयतापघ्नामोपचारस्मास्माद्यं श्रंग
न्यानमयतिन्नानकैःप्रेमाणःशेषोद्भूरस्येव ४७ स्त्रांतमपसारितोपचरणावुपधाय
सुप्तएवासि .उद्घाटयामिकिमूरूनिश्वासैःपुलकयन्नुष्णैः ४८ सूत्तीन्नवस्यकटुतां
प्रकटयतोविदधतश्रमदमुच्चैः मधुनोधमपुरुषस्यचगरिमालघिमाचनेदाय ४९ पू
र्वैर्विनीन्नवृत्तांगुणाढ्यमवनूतिवाणारघुकारैः वाग्देवीमनजतोममसंतःपत्रंपतुका
दोषः ५० सत्पात्रोपनयोचितनावप्रतिबिंबितास्मिनववस्तु कस्यनजनयतिहर्षंस।
काव्यंमधुरवचनंच ५१ सपूत्रसंविधानंसदलंकारंसुवृत्तमाच्छिद्रं कोधारयतिन
कंठेसत्काव्यंमाणिमनर्घंच ५२ राकाधनिद्वितीयात्रिभुनसारस्फुटोक्तिचातुर्या।
पंचेषुहितावणामन्नानंश्रवणास्यसप्तशती ५३ कविसमरसिंहनादस्वरानुवा।
दःसुधैकसंवादः विद्धद्विनोदकंदःसंदर्भोयंमयासृष्टः ५४ उदयनबलभद्राभ्यां

सप्तशतीशिष्यसोदराभ्यांमे द्यौरिवरविचंद्राभ्यांप्रकाशितानिर्मलीकृत्य ५५ ह
रिचरणावामलीलांवामनइवकविपदंलिप्सुः स्वकृतार्यासप्तशतीमेकांगोवर्ध
नाचार्यः ७५६ इतिश्रीमद्गोवर्धनाचार्यविरचितायांसप्तशतीसमाप्ताः श्री
श्रीरांमयनमः श्रीकृष्णायनमः श्रीगुरूभ्यानमः श्रीरांमचंद्र

गणं०श्री०
५४

राम०
५